In Public domain. Digitization Muthulakshmi Research Academy

महा रुद्र यज्ञ

In Public domain. Digitization Muthulakshmi Research Academy

In Public domain. Digitization Muthulakshmi Research Academy

In Public domain. Digitization Muthulakshmi Research Academy

In Public domain. Digitization Muthulakshmi Research Academy

ॐ नमः शिवाय

महा रुद्र यज्ञ

In Public domain. Digitization Muthulakshmi Research Academy

In Public domain. Digitization Muthulakshmi Research Academy

ॐ नमः शिवाय



महा रुद्र यज्ञ

In Public domain. Digitization Muthulakshmi Research Academy

Published by :
Sree Vinayaka Mandir Committee
AB-Block, Vinayaka Mandir Marg,
Sarojini Nagar,
New Delhi-110023 (India)
Tel. : 91-11-24670924, 24105525
E-mail : info@vinayaka.org, svmc1961@gmail.com
Website : //www.vinayaka.org

Dedicated to Lord Sree Vinayaka
on the occasion of
Maha Rudra Yagnam — 2014

First Edition : April, 2004
Second Edition : March, 2006
Third Edition : March, 2009
Fourth Edition : November, 2014

Typeset & Printed by :
Lalit Mohan
Khanoliya Enterprises
New Delhi-110045
Ph. : 9818365568, 9971134689

In Public domain. Digitization Muthulakshmi Research Academy

Sree Vinayaka Mandir Committee (Regd)
Sree Vinayaka Mandir Marg, AB Block,
Sarojini Nagar, New Delhi 110023
Email : info@vinayaka.org, svmc1961@gmail.com
Website : www.vinayaka.org;
Ph. : +91 11 24670924, 24105525

OURSELVES

The South Indian Community of Delhi as far back as 1950 felt the necessity to have a temple in the National Capital for reflecting their rituals and rites. To this end certain philanthropists and citizens of Delhi formed themselves into a Committee known as SREE VINAYAKA MANDIR COMMITTEE which was later registered with the Registrar of Societies, Delhi on the 16th Day of April 1953. The primary objective of the Committee was to install Lord VINAYAKA in the Capital.

A small temple with a "Garbha Griha" for Lord Vinayaka and Prakarams around it was built out of the contributions from the public. With the blessings of His Holiness Paramacharyal of Kanchi Kamakoti Peetam and His Holiness Sree Sankaracharya Swamigal of Sringeri Sharada Peetam, the idols of Sree Siddhi Buddhi Sametha Karpaga Vinayakar was installed on the **24th August 1961** in Sarojini Nagar, built by the Sthapathis from South India.

The Kumbabhishekam was performed in the traditional South Indian Vedic Procedures in the presence of a number of Devotees from different parts of the country. From this humble beginning the Mandir has grown steadily with the ardent devotion and

In Public domain. Digitization Muthulakshmi Research Academy

manificence of the public. It has Vigrahas for Lord Hanuman and the Navagraha Devatas and they attract the attention of the entire devoted public of Delhi. In June 1983 to meet the wishes of the local devotees a temple for Lord Shiva was also consecrated. Here the Bana Linga brought from the Narmada river in Omkareshwar has been installed with the idols of Parvathi, Ganesh and Karthik along with Nandi.

The temple celebrated its 50th year, known as 'GOLDEN JUBILEE YEAR', as "SWARNA JAYANTHI MAHOTSAVAM". During this Swarna Jayanthi Mahotsavam the temple management conducted various types of Vedic, Religious and Cultural Programmes befitting the occasion. At the end of the year long programmes, with the Blessings of lord Vinayaka, **SWARNA BHANDHANA KUMBABHI-SHEKAM, was performed on 19th June 2011.**

Kumbabhishekam is a Vedic ritual required to be performed after every 12 years and after any major repairs to the Temple, by consecrating with Holy waters on the "Kalashas" installed on the crest of the temple tower. It may be noted that so far five Kumba-bhishekams has been conducted in this temple.

The Temple authorities have conducted various types of Maha Yagnas in the past. Following are some of the important Vedic Programmes conducted in this Temple:-

1. Twenty one Maharudra Yagyam (since 1989)
2. Five Athirudram (Every fifth year since 1993)
3. Maha Mrityunjaya Homam (since 2009)

In Public domain. Digitization Muthulakshmi Research Academy

4. Medha Dakshinamoorthy Homam (since 2009)
5. Sahasra Chandi in the year 2000
6. Rig Veda Samhitha Homam
7. Yajur Veda Samhitha Homam
8. Sama Veda Samhita Homam
9. Atharva Veda Samhita Homam
10. Nakshatra Ishti in the year 1993
11. Jata Parayanam in the year 2003
12. Gana Pranayam in the year 2004
13. Veda Class for beginners since 1979 – Daily in the evening
14. Navaham in October 2013 – on the occasion of Installation of Lord Anjaneya and Navagraha idols, Golden Jubilee Celebrations.
15. Brahmayamalokta Navagraha Samuchaya Shanti in October 2013
16. Bhagavatha Sapthaham since 2008

Here we need to mention that the book on **Maharudram** is being published by the Temple Committee, which is very popular among the Vaideegas and Rithviks all over the world.

This is the only Vinayaka Temple wherein the **swapageetham** is recited at the end of the day when Lord Ganesha goes to sleep. There are about 8 slokas that are recited after the Ardhajama Pooja.

In Public domain. Digitization Muthulakshmi Research Academy

These slokas are available on our website also (*www.vinayaka.org*).

Also this is the first Vinayaka Temple wherein the **Siddhi Buddhi Vivaha Paddhathi** was formed and now other temples are also following the same. The Vivaham is being performed every year after Vinayaka Chathurthi celebrations. It is being performed for more than 30 years. The Temple has published a book on the **The Siddhi Buddhi Vinayaka Vivaha Paddhathi.**

The Managing Committee members whole-heartedly desire to place on record our indebtedness and reverance to the dedicated services, blessings and counselling of **Brahmashri T. A. Nagaraja Sastrigal** in the performance of various religious rites and rituals in the temple for over four decades.

These achievements have been possible only with the blessings of Lord Vinayaka and the full cooperation of the Devotees.

In Public domain. Digitization Muthulakshmi Research Academy

Sree Vinayaka Mandir Committee

On the auspicious occasion of the **Twenty First Maha Rudram, 2009** in this Mandir, the Committee with humble devotion and with the blessings of Shree Vinayaka and the Jagadgurus offered the third re-print of the Book **'Maha Rudra Yagnam'**.

The First Edition was brought out on the occasion of Maharudram in 2004. Due to heavy demand, copies were soon exhausted.

A re-print was published during Maharudram 2006. This opportunity was availed of to correct errors and include some more materials. Copies of this were also exhausted due to the increasing popularity of the Book.

The Third Edition with more materials, incorporating corrections in the Maharudram Edition-2006 was released in March, 2009 on the occasion of Maharudra Yagnam-2009. Herein Udaka Shanti Mantra Japam was included.

Copies of this Edition had much publicity with National and International Bhaktas, with the result copies of this Edition-2009 were also completely exhausted.

The Committee has decided now, therefore, to reprint the 2009-Edition with many new additions.

The Committee has no doubt that by the Grace of Sree Vinayaka, this re-print will also meet with the approbation of the Bhaktas and Scholars.

Sree Vinayaka Mandir Committee
November, 2014

In Public domain. Digitization Muthulakshmi Research Academy

प्रस्तावना

विनायक मन्दिर समितिः हर्षमनुभवति गौरवञ्च महारुद्र-यज्ञाख्यस्य ग्रन्थस्य तृतीयावृत्त्याः प्रकाशनेन। प्रथमावृत्तिः 2004 तमे वर्षे प्रकाशिता द्वितीयावृत्तिश्च 2006 तमे वर्षे।

इदानीं पूर्वतन संस्करणे जाता अशुद्धीः संशोध्य, नूतनं परिवर्धितं संस्करणं प्रकाश्यते। अत्र च नाना सूक्तानि, विस्तृतः संकल्पः, जपविधिः, अर्घ्यदानम्, रुद्र चमक क्रम पाठः, इत्यादीनि संयोजितानि सन्ति॥

महान्यासस्य बहुधा पाठभेदो दृश्यते। अत्रत्यः पाठस्तु कुम्भघोणे प्रकाशित पुस्तकानुसारेण वर्त्तते।

यद्यपि मूलं तु बोधायनोक्त महान्यास सूत्राण्येव, मन्त्रपाठः, अनुषंगादिकं तु देशे देशे भिद्यते। "नारुद्रो रुद्रमर्चयेत्। न्यासैः पंचभिः रुद्रमात्मानं भावयति।" इत्युक्तरीत्या महान्यासेन रुद्रोभूत्त्वा रुद्रमर्चयेदिति विधिः॥

रुद्रशब्दस्य अर्थः—रुदं संसार दुःखंद्रावयतीति रुद्रः। "अशुभद्रावको रुद्रो यज्जहारपुनर्भवम्। तस्माच्छिव स्ततो रुद्रशब्देनात्राभिधीयते।" (2) रुतिं शब्दं वेदात्मानं ब्रह्मणे ददाति कल्पादाविति रुद्र इत्यपरे। यथा—"यो वै वेदा॑श्च प्रहिणोति तस्मै।" (3) रोदयति सर्वमन्तकाल इति रुद्रः। इस्यादीनि बहूनि निर्वचनानि भाष्ये प्रदर्शितानि। भट्टभास्कर भाष्ये प्रत्येकस्यापि मन्त्रस्य ऋषिच्छन्दो देवताः दत्ताः। पुरश्चरण विधिश्च विस्तरेणोपदिष्टः॥ एवं महार्णवेऽपि॥

आदित्यात्मकः श्रीरुद्रः अत्र आराध्यते। "असौयस्ताम्रः—असौयोऽवसर्पति इति मन्त्राभ्यां पक्वाहुतिः क्रियते॥ वेदशास्त्र संस्कार रहिता गोपाला अप्येनं मण्डलवर्त्तिनमादित्यरूपिणं रुद्रमदृशन् पश्यन्ति। उदहार्योऽप्येनमदृशन् पश्यन्ति।

In Public domain. Digitization Muthulakshmi Research Academy

एनमादित्यरूपिणं सर्वेऽपि प्राणिनः पश्यन्ति। नीलवर्णा ग्रीवा यस्या सौ नीलग्रीवः। सर्वेषां दर्शनार्थमेव हि रुद्रस्य आदित्य मूर्त्ति धारणम्॥ तादृशो रुद्रो दृष्टस्स अस्मान् मृडयाति सुखिनः करोतु इत्यर्थः॥

"मण्डलान्तरगतं हिरणमयं भ्राजमानवपुषं शुचिस्मितं चण्डदीधितिम खण्डित द्युतिं चिन्तयेन्मुनि सहस्रसेवितम्।"

वस्तुतः श्रीरुद्रः परमकारणं परब्रह्मैव। तदुक्तम्—"परब्रह्मेति विज्ञेयं शिव इत्यक्षरद्वयम्। तद्ब्रह्मेति विदित्वैवं तदुपास्यं मुमुक्षुभिः॥ तदेव सर्ववेदान्त प्रतिपाद्यं न संशयः॥

अतएव आवाहन समये "सनातनं परं ब्रह्म परमात्मानम-व्ययम्। आवाहयामि जगतामीश्वरं परमेश्वरम्" इत्युक्त्वा आवाहयामः।

रुद्राध्यायस्य उपनिषदित्त्यपि प्रसिद्धिः। "एकशत-मध्वर्युशाखाः। तासु रुद्रोपनिषदाम्नायते"—इति हि भट्टभास्कर भाष्यम्॥ श्रुति-स्मृतीतिहास पुराण प्रसिद्धमेव श्रीरुद्रस्य माहात्म्यम्। तच्च अस्मिन् पुस्तके दत्ते संकल्पे सम्यक् संगृहीतमस्ति।

वस्तुतः हरिहरयोः भेद एव नास्ति। इमं विषयं हरिहरा-द्वैतभूषणे श्रीबोधेन्द्र सरस्वती स्वामिनः सम्यङ् निरूपित वन्तः॥

प्रायः सर्वे महर्षयः शिवोपासका आसन्। वसिष्ठेन त्र्यम्बकमन्त्रो दृष्टः। वामदेव एव पंचाक्षर्या ऋषिः। बोधायन महर्षिणा रुद्रजपाभिषेकादयः उपदिष्टाः। एवं शौनक— अगस्त्यादिभिरपि।

भगवान् शिवः अभिषेक प्रियः। बोधायनः—"अथास्य मूर्ध्नि हिरण्य कलशेन सन्ततधारां निषिञ्चेत्। मधुना सर्पिषा पयसा चेक्षुरसेनाम्ररसेन वा तदलाभ उदकेन वा॥"

रुद्रैकादशिन्यामभिषेक द्रव्याणि तु गन्धतैल-पञ्चगव्य पंचामृत-घृत-क्षीर-दधि-मधु-इक्षुसार-फलसार-नालिकेरज-शुद्धोदकानि॥

प्रतिवारं रुद्रजपान्ते चमकानुवाकं पठित्वा पूजा कार्या॥ देवं सम्प्रार्थ्य अर्घ्यदानं कृत्वा साद्गुण्यार्थं फलदानं कुर्यात्॥ मन्त्राः, होमप्रयोगश्च ग्रन्थेऽस्मिन् दत्ताः।

In Public domain. Digitization Muthulakshmi Research Academy

वसोर्धारा। अविच्छिन्नया आज्यधारया अग्नाविष्णू इत्यारभ्य भुवनश्चाधिपतिश्च स्वाहा इत्यन्तं पठन् वसोर्धारां जुहुयात्। "बाहुमात्रां स्रुचं कृत्वा ततस्तम्भ द्वयोपरि। घृतधारां तया सम्यगग्नेरुपरि पातयेत्॥ इति महार्णवे॥ मन्त्रविच्छेदोनकार्य इति वदन्ति। यस्मादस्मिन् समये भगवान् अत्यन्तं प्रसन्नो भवति, अतः भक्तेभ्यः प्रार्थितमभीष्टं प्रददाति।

अश्वमेधादपि अधिक फलप्रद एव महारुद्रयज्ञः। अनेन यज्ञेन सर्वादेवताः प्रीता भवन्ति। महाविष्णुरपि सुप्रीतो भवति "अहं हि सर्व यज्ञानां भोक्ता च प्रभुरेव च" इति गीतोक्तेः। पशुहिंसादिकमत्र किञ्चिदपि नास्ति। अस्मिन् महारुद्रयज्ञे द्रव्ययज्ञ-तपोयज्ञ-स्वाध्याय ज्ञान यज्ञानां सर्वेषामन्तर्भावः। महान् जपयज्ञोऽयं परब्रह्मणः उपासनारूपः।

अहो! "ईश्वर पूजाया महात्म्यं विस्मयावहम्। पत्रमात्रेण सन्तुष्टो यो ददाति निजम्पदम्॥" "ब्रह्मणः सृष्टिकर्त्तृत्वं विष्णोर्दानवमर्दनम्। इन्द्रस्य स्वर्गराज्यञ्च शिवपूजाविधेः फलम्॥" शिव पूजाया माहात्म्यं वर्णयितुं न शक्यते। अधिकं पुराणेभ्यो ज्ञेयम्॥ आह च भगवान् बोधायनः—पापक्षयार्थी व्याधि विमोक्षार्थी श्रीकामश्शान्ति कामः पुष्टिकामस्तुष्टि काम आयुष्यकाम आरोग्य काम एवं कुर्यात्। एवं कुर्वन्सिद्धिम- वाप्नोति॥

एतेन सर्वेषामपि सर्वाभीष्टसिद्धिः सर्वसौभाग्यसिद्धिश्च अवश्यं सम्पत्स्यते॥ अत्र बहुवक्तव्यमवशिष्यते विस्तर भयाद्धि रम्यते॥

भगवत्पाद कृतानि शिवस्तोत्राणि, शिवानन्दलहरी, पुष्पदन्तकृतं शिवमहिम्नः स्तोत्रम्, अप्पय्य दीक्षित कृता आत्मार्पणस्तुतिः, नीलकण्ठदीक्षितकृता शिवोत्कर्षमञ्जरी इत्यादीनि यथावकाशं पठनीयानि॥

इदं परिवर्द्धितं संस्करणं सर्वेषामास्तिकानां वैदिकानाञ्च महते उपकाराय भविष्यति। आस्तिकाश्च अस्य ग्रन्थस्य परिग्रहेण अस्माकं परिश्रमं सफलं करिष्यन्तीति सुदृढं विश्वस्यते॥

इति

विनायक मन्दिर समितिः

In Public domain. Digitization Muthulakshmi Research Academy

वागीशाद्याः सुमनसः सर्वार्थानामुपक्रमे।
यं नत्वा कृतकृत्त्याः स्युस्तं नमामि गजाननम्॥
सर्वाभीष्टप्रदातारं सिद्धिबुद्धि समन्वितम्।
महागणपतिं वन्दे सरोजिनी पुरस्थितम्॥

विनायक मन्दिरे प्रचलिताः कार्यक्रमाः

सप्तचत्वारिंशद्वर्षेभ्यः पूर्वं (1961 मार्च् मासस्य 21 तमे दिने) परमेश्वरस्य कृपया जगद्गुरूणामनुग्रह बलाच्च सिद्धि बुद्धि समेत श्री कल्पक विनायक मन्दिर मे तत् स्थापितम्। भक्ताञ्जनेयार्थं, नवग्रह देवतार्थं मोंकारेश्वरार्थञ्च सन्निधयः कल्पिताः। भक्तजनानां श्रद्धया, भक्त्या, प्रचुर धन दानादिभिश्च मन्दिर मे तद् महतीं वृद्धिं प्राप। देवतानां सान्निध्यमहरहः अवर्धत॥ इदानी मेतत्क्षेत्रं वेदविद्यानां नानाविध कलानाञ्च केन्द्रं संवृत्तम्॥

(1) अत्रहि विनायक चतुर्थी समये दशदिनपर्यन्तं ब्रह्मोत्सवः प्रवर्त्तते। चत्वारिंशद् दिनानि यावत् विनायकस्य लक्षार्चनं क्रियते।

तदा चतुर्वेद संहिता पारायणं, सहस्रनाम होमः अथर्वशीर्ष हवनं, अश्टद्रव्य होमः, इत्यादिकं महता वैभवेन क्रियते। सार्धमेव भजन रीत्या अखण्ड सुन्दरकाण्ड पारायणं, सिद्धि बुद्धि विवाहः, संगीत कार्यक्रमः, प्रवचनादिकं च प्रचलति।

(2) तथैव हनुमज्जयन्ती समये शंकरजयन्ती समये च सीता विवाहः, पुरुषसूक्त होमः, श्रीसूक्तहोमश्च क्रियन्ते।

(3) नवरात्रि समये चण्डी होमः, लक्षार्चनं, इत्यादिकं प्रचलति॥

असंख्यानि खलु अत्रत्यानि वैदिक कार्याणि॥

1. प्रतिभानुवासरं अरुणप्रश्न पठनेन सूर्यनमस्काराः क्रियन्ते॥

2. प्रतिमासं द्वितीये रविवासरे महान्यास पुरस्सरः रुद्राभिषेकः वर्त्तते।

3. भृगुवारेषु महिलाभिः ललिता सहस्रनाम पारायणं क्रियते।

In Public domain. Digitization Muthulakshmi Research Academy

महाशिवरात्रि काले ओंकारेश्वरस्य महान्यासपूर्वक एकादशवार रुद्राभिषेकः क्रियते॥

मार्च् मासस्य 21 तमे दिने सूर्यपूजा प्रवर्त्तते।

वसन्त नवरात्रि समये श्रीसूक्तहोमः समायोज्यते।

तुला पूर्णिमायां अन्नाभिषेकः, वृश्चिकमासे शंखाभिषेकश्च क्रियेते॥

शनैश्चरस्य नूतन राशि प्रवेश समये शनैश्चर शान्तिः क्रियते। एवं गुरोरपि राशिसंक्रमणकाले गुरुशान्तिः क्रियते। तदा नवग्रह होमोऽपि अति विस्तृत रीत्या क्रियते॥

प्रतिवर्षं महारुद्रयज्ञः शताधिकैः ऋत्विग्भिः प्रवर्त्तितो भवति।

शंकर जयन्त्यां च वेदपारायण मावहन्ती होमश्च क्रियेते॥

वेद संहिता होमाश्च प्रवर्त्तन्ते।

मन्दिरे वेदपाठशालाऽपि वर्त्तते। अत्र बालकेभ्यः उपयुक्त वेदभागा अध्याप्यन्ते।

समये समये रामायण भागवतादि प्रवचनानि आयोज्यन्ते।

अखण्ड रामायण-भागवतादि मूल परायणमपि प्रवर्त्तते।

अस्मिन् देवालये तैत्तिरीयसंहितायाः, ऋग्वेदसंहितायाश्च जटापाठ-घनपाठादिकमपि बहुवारं प्राचलत्। सम्पूर्णस्य यजुर्वेदस्य घनपाठः वारत्रयं प्रवृत्तम्। अत्यपूर्वस्य जैमिनीयस्य सामवेदस्यापि पारायणं चलति स्म।

गुरुवायूरेकादशी समये अखण्ड नारायणीय पठन मा योज्यते॥

इतः पूर्वम् अत्र चतुर्वारम् अतिरुद्र महायज्ञः प्रावर्त्तत॥ शतचण्डी यागः चतुर्वारं प्रावर्त्तत।

परमकारुणिकः भगवान् महागणपतिः प्रचुरमात्रया अनुग्रह वृष्टिं, सुवर्ण वृष्टिं, ईप्सितार्थ वृष्टिञ्च कुर्वन् विराजते॥

In Public domain. Digitization Muthulakshmi Research Academy

श्री काञ्ची कामकोटि पीठम्

बिरुदावलिः

॥ श्री गुरुभ्यो नमः ॥

॥ श्रीचन्द्रमौलीश्वराय नमः ॥

स्वस्ति श्रीमदखिल-भूमण्डलालङ्कार- त्रयस्त्रिंशत्कोटि-देवतासेवित- श्रीकामाक्षी- देवी- सनाथ- श्रीमदेकाम्रनाथ-श्रीमहादेवीसनाथ- श्रीहस्तिगिरिनाथ- साक्षात्कार- परमाधिष्ठान-सत्यव्रतनामाङ्कित- काञ्ची- दिव्यक्षेत्रे; शारदा- मठ-सुस्थितानाम्; अतुलित- सुधारस- माधुर्यकमलासन- कामिनी, धम्मिल- सम्फुल्ल- मल्लिका-मालिका- निष्यन्द- मकरन्द-झरी- सौवस्तिक- वाङ्निगुम्भ- विजृम्भणानन्द- तुन्दिलित-मनीषि- मण्डलानाम्; अनवरताद्वैत- विद्या- विनोद- रसिकानां; निरन्तरालङ्कृतीकृत- शान्ति- दान्ति- भूम्नाम्; सकलभुवन-चक्र-प्रतिष्ठापक-श्रीचक्र-प्रतिष्ठा-विख्यात-यशोऽलङ्कृतानाम्; निखिल- पाषण्ड- षण्ड- कण्टकोत्पाटनेन विशदीकृत; वेद-वेदान्त- मार्ग- षण्मत- प्रतिष्ठापकाचार्याणाम्; श्रीमत्परमहंस-परिव्राजकाचार्यवर्य-श्रीजगद्गुरु- श्रीमच्छङ्कर- भगवत्पादा-चार्याणाम्; अधिष्ठाने सिंहासनाभिषिक्त- श्रीमच्चन्द्रशेखरेन्द्र-सरस्वती- संयमीन्द्राणाम्; अन्तेवासिवर्य- श्रीमज्जयेन्द्र-सरस्वती-श्रीपादानां; तदन्तेवासिवर्य- श्रीमच्छङ्कर- विजयेन्द्र-सरस्वती- श्रीपादानां; चरणारविन्दयोश्च समर्प्यन्ते अनेक-कोटि- साष्टाङ्गप्रणामाः ॥

हर हर शङ्कर जय जय शङ्कर

In Public domain. Digitization Muthulakshmi Research Academy

॥ गुरुवन्दनम् ॥

शृङ्गगिरि जगद्गुरु महासंस्थानं शारदा पीठम्

बिरुदावलिः

॥ श्री गुरुभ्यो नमः ॥

॥श्रीशारदाचन्द्रमौलीश्वराभ्यां नमः ॥

श्रीमत्परमहंस परिव्राजकाचार्यवर्य, पदवाक्यप्रमाण पारावारपारीण, यमनियमासन प्राणायाम प्रत्याहार, धारणा ध्यानसमाध्यष्टाङ्ग योगानुष्ठाननिष्ठ, तपश्चक्रवर्ति, अनाद्य-विच्छिन्न श्री शंकराचार्य गुरुपरंपराप्राप्त, षड्दर्शन स्थापनाचार्य, व्याख्यानसिंहासनाधीश्वर, सकल निगमागम-सारहृदय, सांख्यत्रय प्रतिपादक, वैदिकमार्गप्रवर्तक, सर्वतन्त्र स्वतन्त्र, आदिराजधानी विद्यानगरमहाराजधानी, कर्णाटक-सिंहासन प्रतिष्ठापनाचार्य, श्रीमद्राजाधिराजगुरु भूमण्डलाचार्य, ऋष्यशृङ्गपुरवराधीश्वर, तुङ्गभद्रातीरवासि, श्रीमद्विद्याशंकर पादपद्माराधक, श्रीजगद्गुरु श्रीमदभिनवविद्यातीर्थ महास्वामि गुरुकरकमलसञ्जात, श्रीजगद्गुरु श्री श्रीभारतीतीर्थ महास्वामिनां चरणारविन्दयोः, सादरं सविनयं साञ्जलिबन्धं सप्रणिपातशतं साष्टाङ्ग नमस्कारान् समर्पयामः ॥

In Public domain. Digitization Muthulakshmi Research Academy

॥ श्रीविद्या पातु मां सदा ॥

श्री श्री जगद्गुरु बदरी शङ्कराचार्य महासंस्थानम्

शकटपुर श्रीविद्यापीठम्, भण्डिगडि

स्वस्ति! श्रीमदखिलजगद्विद्योतमानहृद्यानवद्याद्य- विद्याद्युति-खद्योतीकृतभेदविद्यानां, प्रणवमनुस्मरणार्हणा प्रणयप्रीणितस्मरहरण-भवतरण- नतशरण-जितकरण- शर्वाणी- रमणरमणीयचरण-श्रीपर्णनां, सर्वसर्वसहासञ्चरण- देवपरिचरण-विध्याचरण-स्तवकरण-भक्तचिद्धरण- समेधितसदाधारसनातनधर्मधाम्नां, पाषण्डमतषण्ड-खण्डनोद्दण्ड प्रकाण्डपाण्डितीसम्मण्डिताशामण्डलानां, आर्यवर्य-पराशर्यवचःकार्यभाष्यसपर्यापर्यायमोदितार्यधुर्याणां, अभिरूपवल्लभ-सम्भायक सभासम्भावितकलासम्भृताम्भो- भवभूभामिनीभ्रूभंगा-भिमानसम्भेदकानां, विगातनीति- वसुमतीपति सुनीतिबोधनाधीनीकृत-यशोधनानां, निखिल- विपुलातलसञ्चलनसञ्चालितदाशबलकोलाहल बला- वलेपविदलनविलास- कलिताद्वैतमतमतल्लिकोल्लासितो-पलब्धिमल्लेखानां, मोहग्राहनिर्हरणहरिप्रहरणायमानानां, दनीध्वस्त-समस्तनास्तिकस्तोम- विस्तृतवाग्विस्तराणां, श्रीमत्परमहंसपरिव्राज-काचार्यवर्यसच्चर्य- भगवदाचार्य जगद्गुरु श्रीशङ्करभगवत्पूज्यपादानां, सच्छिष्यवर्य जगद्गुरूत्तराम्नाय- जेतिष्पीठाधीश्वर श्रीमदाचार्यतोटक-भगवत्पाद- प्रवर्तितसद्गुरु परम्पराविभ्राजमान श्रीमत्सत्यतीर्थ-सत्सम्प्रदाय विलसिततुङ्गा- भद्रातीरनिवास शकटाख्यमहर्षिपरिपावित-श्रीशकटपुराधीश्वर- श्रीगुरुदत्तात्रेय- चन्द्रमौलीश्वरश्रीविद्या-विश्वेश्वर-श्रीविद्या- म्बिकाश्रीमद्राजराजेश्वरी- श्रीसन्तानवेणुगोपाल-कृष्ण पाद- पद्माराधकश्रीविद्यापीठाधीश्वर-जगद्गुरु श्रीमद्रामचन्द्रा-नन्दतीर्थ- महास्वामिगुरुकरकमलानुग्रहसञ्जात जगद्गुरु श्रीविद्याभिनव श्रीकृष्णानन्दतीर्थ स्वामि-पादारविन्दयोः साष्टाङ्ग प्रणामाः ॥

In Public domain. Digitization Muthulakshmi Research Academy

१. यो देवानां प्रथमं पुरस्तात् विश्वाधियो रुद्रो महर्षिः।
हिरण्यगर्भं पश्यत जायमान ँ सनो देव शशुभया स्मृत्या स्संयुनक्तु॥
२. यस्मात्परन्नापर मस्ति किञ्चिद्यस्मान्नाणीयो नज्यायोऽस्ति कश्चित्।
वृक्ष इव स्तब्धो दिवि तिष्ठ त्येक स्तेनेदं पूर्णं पुरुषेण सर्वम्॥
३. न कर्मणा न प्रजया धनेन त्यागेनैके अमृतत्वमानशुः।
परेण नाकं निहितं गुहायां विभ्राजदेत द्यतयो विशन्ति॥
४. वेदान्त विज्ञान सुनिश्चितार्था स्सन्यास योगा द्यतय शशुद्ध सत्वाः।
ते ब्रह्म लोकेतु परान्तकाले परामृतात्परिमुच्यन्ति सर्वे॥
५. दहं विपापं परमेऽश्म भूतं यत्पुण्डरीकं पुरमध्य स ँ स्थम्।
तत्रापि दहं गगनं विशोक स्तस्मिन् यदन्त स्तदुपासि तव्यम्॥
६. यो वेदादौ स्वरः प्रोक्तो वेदान्ते च प्रतिष्ठितः।
तस्य प्रकृति लीनस्य यः परस्स महेश्वरः॥

सदाशिव समारम्भां शंकराचार्य मध्यमाम् अस्मद् आचार्य
पर्यन्तां
वन्दे गुरु परम्पराम्॥
॥ॐ नमः शिवाय॥

In Public domain. Digitization Muthulakshmi Research Academy

Maha Rudra Yagnam

The Vedas are supreme among the various forms of knowledge and Vedas have to be learnt and understood for their own sake without expecting any reward. That is why our ancients had thought best to utilise various portions of the Veda Mantras for purposes of rituals and ceremonies for conferring spiritual as well as material benefits on mankind since they knew that very few people would learn Vedas merely for their own sake in these days.

The word Shiva is considered by the sages as JIVARATNA or the jewel of life.

That life jewel praised by all the Vedas and also called Sankara, Tryambaka etc., is the only refuge for all living beings and gives all happiness in life. To worship such an incomparable form, all devotees of Shiva used to observe the following five rules.

(1) Rudraksha Dharanam; (2) Bhasma Dharanam in the prescribed manner; (3) Panchakshara Mantra Japa by those who have been initiated by a Guru or Shiva Nama Japa by those not initiated into the Mantra, (4) Performing daily Panchayatana Puja and (5) Meditating constantly on Sadashiva.

Ancient sages and saints have prescribed several ceremonies and austerities where Vedic Mantras are used for worship. One of such Mantras of high potency and power is called SRI RUDRAM of Taitriya Samhita of Sri Krishna Yajurveda. The Samhita consists of seven 'cantos' containing 44 Chapters or 'Prashnas'. In the middle of 4th Canto of this Samhita 'SRI RUDRAM' is the

In Public domain. Digitization Muthulakshmi Research Academy

fifth chapter (Prashna). This chapter is divided into 11 'Anuvakas' or paragraphs. It is a prayer to Lord Shiva praising His various attributes and qualities. The importance of Sri Rudram is that it occurs in the middle of the Taittiriya Samhita and in the central portion of Sri Rudram is to be found the greatest of the Mantras viz. The PANCHAKSHARA MANTRA. Sri Rudram is therefore the holiest of holy Mantras. It is also called Namaka Prashnam as the word NAMAHA occurs several times. It is also known as Shatharudriyam. It is recited not only for one's own purification and attainment of higher spiritual knowledge but also for bringing welfare to oneself and to the country as a whole. To preserve the maximum power and efficacy of the Mantras, the method of chanting has also been prescribed. Even the mere recitation with devotion and repetition of Sri Rudra Prashna is believed to please Lord Shiva. Traditionally, the seventh chapter of the 4th Cantos of Taittiriya Samhita called the CHAMAKA Prashnam is also recited along with Sri Rudra Prashnam in which there is a prayer for seeking material benefits ranging from material needs such as food to eat, to achieve ultimate salvation. Sanyasis are not used to recite this Chamaka Prasna as naturally they have no need for material benefits.

Constant repetition of Rudra Mantras in the prescribed manner is called JAPA YAGNA. This Japa Yagna is followed by Abhisheka, Havan and Archana to Lord Shiva by which the efficacy of the Japa Yagna is enhanced.

Sri Rudra Japam is normally done after an elaborate Anganyasa which is called MAHANYASA. Sri Rudram is then chanted eleven times and at the end, one Anuvaka

In Public domain. Digitization Muthulakshmi Research Academy

of Chamaka Prashnam is chanted. Thus when Sri Rudram is chanted 11 times, Chamakam is chanted once in full; i.e., the first eleven anuvakas of the seventh prashna of the 4th canto of Taitriya Samhita. Simultaneously, Abhishekam is also performed on a 'Shivalinga' chanting Sri Rudra eleven times and Chamaka once. The significance is that, the eleven forms of Lord Shiva viz: Mahadeva, Shiva, Rudra, Sankara, Neelalohita, Eashana, Vijaya, Bhima, Devadeva, Bhavodhbhava and Adityatmaka Rudra, are invoked in eleven Kalashas (Kumbham) when eleven Pundits chant Sri Rudra Mantra eleven times each according to the above procedure followed by one anuvaka of chamaka. Then Havan is performed chanting Rudra and Chamaka Prashna in full and pouring pure cow's ghee into the fire in one unbroken thread-like stream chanting Chamaka Prashna called VASORDHARA. Abhishekam is also performed with the water sanctified in the eleven Kumbhams to the Lord while the same is also sprinkled on all the devotees assembled to witness the Maharudra Yagna. Then Archana is performed with flowers and 'Bilwa' leaves with various Mantras. The Yagna is then concluded with Mangala Harati and Mantra Pushpanjali.

In this Rudraikadasini, as it is called, Sri Rudra Mantra is chanted 121 times by 11 pundits each chanting 11 times and the Chamaka Mantra is chanted 11 times, each pundit chanting once in addition to the chant required for Abhisheka, Archana and Havan. ELEVEN such RUDRAIKADASINIS (i.e. 11x11x11) are required to be performed for a MAHA RUDRA YAGNA; i.e., 11 pundits duly initiated and trained in Vedas and knowing

In Public domain. Digitization Muthulakshmi Research Academy

the various Mantras required for chanting according to the proper Swaras. At the time of Rudra Japa, there should be purity in all the three Karanas—Mano, Vak and Kaya—Mind, speech and body. The body should be clean after bath and sacred Bhasma should adorn the body along with Rudraksha beads. To prevent laziness, indifference, inattention and tendency to sleep, preferably one should not take any food before chanting the Mantras. The Maharudram is usually done for 11 days but to save time depending on local condtions, it may be done in 4 or 5 days according to the availability of more Pundits, time and resources. Altematively, 11 groups (GANAS) of 11 Vedic Pundits each can conduct the Maharudra Yagna in one day also, each group performing one (RUDRAIKADASINI).

Eleven such Maharudra Yagna [i.e. 11x(11x11x11)] performed without break i.e., 121 Rudrikadasinis will be required for one ATI RUDRA MAHA YAGNA. These 121 Rudrikadasinis can be performed by 121 Vedic Pundits for eleven days consecutively or 11 Vedic Pundits consecutively for 121 days. What is important is the total number of times the Rudra Mantras are chanted accompanied by the Chamaka Mantras. The number of days and the number of Pundits may be modified according to convenience. But this modification has to be done only according to the prescribed procedure so that the essentials are not left out.

The greatness of these Mantras and the unique benefits which flow from the performance of Yagnas to the accompaniment of such Mantras have been described in detail in the ancient text SIVA RAHASYA. To quote some of them:

In Public domain. Digitization·Muthulakshmi Research Academy

(a) Performance of Karma Kanda rituals lead to the cleaning of the mind as a preparatory to the acquisition of Brahma Vidya.

(b) Expiation of sins and removal of obstacles to progress and prosperity.

(c) Securing ultimate salvation.

The superior excellence of SRI RUDRA MANTRAS have been brought out in the SUTA SAMHITA in SKANDA PURANA.

Satarudriyam occurs in all the 100 sakhas of Yajurveda and by the mere chanting, one's all sins are destroyed.

The SMRITIS also refer to Sri Rudra as a panacea for the expiation of unrighteous acts. e.g., the Smiritis of Satatapah, Atri and Yagnavalkya.

Bodayana prescribes Rudra Japa with Mahanyasa for one who is a Papakashayarthi, Vyadhimochanarthi, SRIKAMAH, SANTIKAMAH, Ayushyakamah and Aroghyakamah i.e., who wants atonement from sins, relief from disease, wealth, long life and sound health with peace.

The chanting of Sri Rudra is prescribed for Sanyasins also.

In Hari Vamsa there is a reference to Sri Krishna having performed Rudra Japa. Although in reality, there is no need for Sri Krishna for performing any Japa, yet He resorted to the same for the benefit of the people at large.

LOKAH SAMASTHAH SUKHINO BHAVANTHU

In Public domain. Digitization Muthulakshmi Research Academy

अनुक्रमः

- Sri Vinayaka Mandir Committee—Ourselves v
- Sri Vinayaka Mandir Committee—Need for 4th Edition ix
- प्रस्तावना x
- विनायक मन्दिरे प्रचलिताः कार्यक्रमाः xiii
- बिरुदावलिः श्री काञ्ची कामकोटि पीठम् xv
- बिरुदावलिः शृङ्गगिरि जगद्गुरु महासंस्थानं शारदापीठम् xvi
- बिरुदावलिः श्री श्री जगद्गुरु बदरी शङ्कराचार्य महासंस्थानम् xvii
- Maha Rudra Yagnam (A short note) xix

महारुद्र यज्ञम्

1. स्वस्ति वाचनम् (प्रार्थना) 1
2. गणपत्यथर्वशीर्षोपनिषत् 1
3. फलश्रुतिः 3
4. अनुज्ञा 4
5. विघ्नेश्वर पूजा 6
6. संकल्पः 8
7. ग्रह प्रीतिः 16
8. गोदानम् 16
9. नान्दी श्राद्धम् 16
10. वैष्णव श्राद्धम् 17
11. पूतत्व कृच्छ्रम् 18
12. दशदानम् 18
13. पञ्चदानम् 20
14. पुण्याहवाचनम् 21
15. पवमान सूक्तम् 23
16. आचार्य ऋत्विक् वरणम् 26
17. कलश पूजा 26

In Public domain. Digitization Muthulakshmi Research Academy

18. शंख पूजा 26
19. कलश आवाहनम् 27
20. महान्यास मंत्र पाठ प्रारंभः 29
- पंचांग रुद्र न्यासः 29
- पंचमुख न्यासः 30
- केशादि पादान्त न्यासः 32
- दशांग न्यासः 36
- पंचांग न्यासः 36
- हंस गायत्री 37
- ध्यानम् 37
- दिक् संपुट न्यासः 37
- षोडशांग रौद्रीकरणम् 40
- गुह्यादि मस्तकान्तं षडंग न्यासः 44
- आत्म रक्षा 44
- शिव संकल्पः 45
- पुरुष सूक्तम् 49
- उत्तर नारायणम् 51
- अप्रतिरथम् 51
- प्रतिपूरुषम् 53
- त्वमग्ने रुद्रोऽनुवाकः 54
- पञ्चाङ्ग जपः 57
- अष्टाङ्ग प्रणामः 58
- लघु न्यासः 59
- अंग न्यासः 59
- कलशेषु ध्यानम् 61
- आवाहनः 62
- प्राण प्रतिष्ठा 63
- ध्यानम् 63

In Public domain. Digitization Muthulakshmi Research Academy

- आसनादि उपचाराः 64
- अर्चना 66
- श्री शिवाष्टोत्तर शतनामावळिः 67
- श्री गणेश अष्टोत्तर शतनामावळिः 69
- श्री विनायक अष्टोत्तर शतनामावळिः 71
- श्री आंजनेय अष्टोत्तर शतनामावळिः 74
- श्री नवग्रह अष्टोत्तर शतनामावळिः 76
- श्री सुब्रह्मण्य अष्टोत्तर शतनामावळिः 78
- श्री दुर्गा अष्टोत्तर शतनामावळिः 81
- श्री दक्षिणामूर्ति स्तोत्रम् 83
- श्री दक्षिणामूर्ति अष्टोत्तर शतनामावळिः 84
- श्री नन्दिकेश्वर अष्टोत्तर शतनामावळिः 86
- श्री लिंगाष्टोत्तर शतनामावळिः 89
- श्री परमेश्वर-ललिता अष्टोत्तर शतनामावळिः 92
- धूप दीपादि उपचाराः 101
- श्रीरुद्रनाम त्रिशती 102
- प्रदक्षिण मन्त्रः 107
- नमस्कार मन्त्रः 108
- प्रार्थना-चमक प्रश्नः 109
- श्री रुद्र प्रश्नः न्यासः 113
- ध्यानम् 114
- श्री रुद्र प्रश्नः (नमकम्) 115
- श्री चमक प्रश्नः 122
- प्रत्येक चमकानुवाक जपानन्तरं कर्पूर नीराजन मंत्राः 126
- गायत्री मन्त्राः प्रतिवार जपान्ते 127
- प्रार्थना-अर्घ्यं, साद्गुण्यं प्रतिवार जपान्ते 128
- अर्घ्यश्लोकाः 128
- अर्घ्यदानम् 130

In Public domain. Digitization Muthulakshmi Research Academy

- रुद्रजपानन्तर प्रार्थना स्वस्ति मन्त्राः 143

21. श्री रुद्र होमः — रुद्रैकादशिन्यां, महारुद्रे, अतिरुद्रे च प्रयोग विधिः 149
22. आपस्तंब अग्निमुख प्रयोगः 150
23. स्विष्टकृत होमः 154
24. वसोर्धारा विधानम् 154
25. जयादि होमः 155
26. पूर्णाहुतिः 162
27. दीपाराधना, मन्त्रपुष्पम्, प्रदक्षिण नमस्कारा: 165
28. प्रोक्षण मन्त्राः 166
29. श्री रुद्र क्रम पाठः 167
30. श्री चमक क्रम पाठः 186
31. हारती उपचार मंत्राः 197
32. अलंकार दीपः 197
33. क्षमा प्रार्थना 201
34. बिल्वाष्टोत्तर शतनाम स्तोत्रम् 202
35. शिव मानस पूजा 211
36. शिव पंचाक्षर स्तोत्रम् 212
37. लिंगाष्टकम् 212
38. श्री बिल्वाष्टकम् 213
39. श्री मार्गबन्धु स्तोत्रम् 214
40. श्री वैद्यनाथाष्टकम् 215

APPENDICES

1. पुरुष सूक्तम् 217
2. नारायण सूक्तम् 219
3. विष्णु सूक्तम् 220
4. दुर्गा सूक्तम् 221
5. श्री सूक्तम् 222

In Public domain. Digitization Muthulakshmi Research Academy

6. भू सूक्तम् 225
7. नीळा सूक्तम् 227
8. मेधा सूक्तम् 227
9. देवी सूक्तम् 228
10. भाग्य सूक्तम् 229
11. ओषधि सूक्तम् 229
12. श्री गणेश सूक्तम् 231
13. मन्यु सूक्तम् 232
14. ब्रह्म सूक्तम् 233
15. रुद्र सूक्तम् 234
16. ओदन सूक्तम् (अन्न सूक्तम्) 235
17. नवग्रह सूक्तम् 242
18. नक्षत्र सूक्तम्—अष्टवाक्यम् स्वाहाकारश्च 249
19. शान्ति पंचकम् (पंच शान्तयः) 258
20. सरस्वती सूक्तम् 260
21. त्रिसुपर्ण मन्त्राः 261
22. घृत सूक्तम् 262
23. मृत्यु सूक्तम् 263
24. आयुष्य सूक्तम् 264
25. घोष शान्तिः 265
26. उदक शान्तिः 268
27. अभिषेक द्रव्याणि 298
28. विभूति अभिषेक मन्त्राः 298
29. दक्षिणामूर्त्युपनिषत् 300
30. श्री दक्षिणामूर्ति अष्टकम् 303
31. तोटकाष्टकम् 305
32. मन्त्र पुष्पम् 306
33. ओं नमो ब्रह्मणे (त्रिवारं) 307

In Public domain. Digitization Muthulakshmi Research Academy



Lord Ganesha with Siddhi & Buddhi — Sree Vinayaka Mandir

In Public domain. Digitization Muthulakshmi Research Academy



Sree Vinayaka Mandir — 1961

Sree Vinayaka Mandir — 2014

In Public domain. Digitization Muthulakshmi Research Academy

॥ स्वस्ति वाचनम् (प्रार्थना) ॥

गणानां त्वा गणपतिं हवामहे कविं कवीना-मुपमश्र वस्तमम्। ज्येष्ठराजं ब्रह्मणां ब्रह्मणस्पत आ नः श्रृण्वन्नूति-भिस्सीद सादनम्॥ ओं श्री महागणपतये नमः॥

॥ गणपत्यथर्वशीर्षोपनिषत् ॥

ॐ भद्रं कर्णेभिः शृणुयाम देवाः। भद्रं पश्येमाऽक्ष-भिर्यजत्राः। स्थिरैरङ्गैस्तुष्टुवांसस्तनूभिः। व्यशेम देवहितं यदायुः। स्वस्ति न इन्द्रो वृद्धश्रवाः। स्वस्ति नः पूषा विश्ववेदाः। स्वस्ति नस्तार्क्ष्यो अरिष्टनेमिः। स्वस्ति नो बृहस्पतिर्दधातु॥

ॐ शान्तिः शान्तिः शान्तिः॥

ॐ नमस्ते गणपतये। त्वमेव प्रत्यक्षं तत्त्वमसि। त्वमेव केवलं कर्ताऽसि। त्वमेव केवलं धर्ताऽसि। त्वमेव केवलं हर्ताऽसि। त्वमेव सर्वं खल्विदं ब्रह्मासि। त्वं साक्षादात्माऽसि नित्यम्॥१॥

ऋतं वच्मि। सत्यं वच्मि॥२॥

अव त्वं माम्। अव वक्तारम्। अव श्रोतारम्। अव दातारम्। अव धातारम्। अवानूचानमव शिष्यम्। अव पश्चात्तात्। अव पुरस्तात्। अवोत्तरात्तात्। अव दक्षिणात्तात्। अव चोर्ध्वात्तात्। अवाधरात्तात्। सर्वतो मां पाहि पाहि समन्तात्॥३॥

त्वं वाङ्मयस्त्वं चिन्मयः। त्वमानन्दमयस्त्वं ब्रह्ममयः। त्वं सच्चिदानन्दाऽद्वितीयोऽसि। त्वं प्रत्यक्षं ब्रह्मासि। त्वं ज्ञानमयो विज्ञानमयोऽसि॥४॥

In Public domain. Digitization Muthulakshmi Research Academy

सर्वं जगदिदं त्वत्तो जायते। सर्वं जगदिदं त्वत्तस्तिष्ठति। सर्वं जगदिदं त्वयि लयमेष्यति। सर्वं जगदिदं त्वयि प्रत्येति। त्वं भूमिरापोऽनलोऽनिलो नभः। त्वं चत्वारि वाँक्पदानि॥५॥

त्वं गुणत्रयातीतः। त्वं देहत्रयातीतः। त्वं कालत्रयातीतः। त्वं मूलाधारेस्थितोऽसि नित्यम्। त्वं शक्तित्रयात्मकः। त्वां योगिनो ध्यायन्ति नित्यम्। त्वं ब्रह्मा त्वं विष्णुस्त्वं रुद्रस्त्वमिन्द्र-स्त्वमग्निस्त्वं वायुस्त्वं सूर्यस्त्वं चन्द्रमास्त्वं ब्रह्म भूर्भुव स्सुवरोम्॥६॥

गणादिँ पूर्वमुच्चार्य वर्णादिँ तदनन्तरम्। अनुस्वारः परतरः। अर्धेँन्दुलसितम्। तारेण ऋद्धम्। एतत्तव मनु-स्वरूपम्। गकारः पूर्वरूपम्। अकारो मध्यमरूपम्। अनुस्वार-श्चाँन्त्यरूपम्। बिन्दुरुत्तररूपम्। नादः सन्धानम्। सꣳहिता सन्धिः। सैषा गणेशविद्या। गणक ऋषिः। निचृद्गायत्रीच्छन्दः। गणपतिर्देवता। ॐ गं गणपतये नमः॥७॥

एकदन्ताय विद्महे वक्रतुण्डाय धीमहि। तन्नो दन्तिः प्रचोदयात्॥८॥

एकदन्तं चतुर्हस्तं पाशमङ्कुशधारिणम्। अभयं वरदं हस्तैर्बिभ्राणं मूषकध्वजम्॥ रक्तं लम्बोदरं शूर्पकर्णकं रक्तवाससम्। रक्तगन्धानुलिप्ताङ्गं रक्तपुष्पैः सुपूजितम्॥ भक्तानुकम्पिनं देवं जगत्कारणमच्युतम्। आविर्भूतं च सृष्ट्यादौ प्रकृतेः पुरुषात्परम्॥ एवं ध्यायति यो नित्यं स योगी योगिनां वरः॥९॥

In Public domain. Digitization Muthulakshmi Research Academy

नमो व्रातपतये नमो गणपतये नमः प्रमथपतये नमस्तेऽस्तु लम्बोदरायैकदन्ताय विघ्ननाशिने शिवसुताय श्री वरदमूर्तये नमो नमः ॥१०॥

॥ फलश्रुतिः ॥

एतदथर्वशीर्षं योऽधीते। स ब्रह्मभूयाय कल्पते। स सर्वविघ्नैर्न बाध्यते। स सर्वत्र सुखमेधते। स पञ्चमहापापात् प्रमुच्यते। सायमधीयानो दिवसकृतं पापं नाशयति। प्रातरधीयानो रात्रिकृतं पापं नाशयति। सायं प्रातः प्रयुञ्जानो पापोऽपापो भवति। सर्वत्राधीयानोऽपविघ्नो भवति। धर्मार्थकाममोक्षं च विन्दति। इदमथर्वशीर्षमशिष्याय न देयम्। यो यदि मोहाद् दास्यति स पापीयान् भवति। सहस्रावर्तनात् यं यं काममधीते। तं तमनेन साधयेत्॥११॥

अनेन गणपतिमभिषिञ्चति। स वाग्मी भवति। चतुर्थ्यामनश्नन् जपति। स विद्यावान् भवति। इत्यथर्वणवाक्यम्। ब्रह्माद्यावरणं विद्यात्। न बिभेति कदाचनेति॥१२॥

यो दूर्वाङ्कुरैर्यजति। स वैश्रवणोपमो भवति। यो लाजैर्यजति। स यशोवान् भवति। स मेधावान् भवति। यो मोदकसहस्रेण यजति। स वाञ्छितफलमवाप्नोति। यःसाज्यसमिद्भिर्यजति। स सर्वं लभते। स सर्वं लभते॥१३॥

अष्टौ ब्राह्मणान् सम्यग् ग्राहयित्वा। सूर्यवर्चस्वी भवति। सूर्यग्रहे महानद्यां प्रतिमासन्निधौ वा जप्त्वा। स सिद्धमन्त्रो भवति। महाविघ्नात् प्रमुच्यते। महादोषात् प्रमुच्यते। महापापात् प्रमुच्यते। स सर्वविद्भवति स सर्वविद् भवति। य एवं वेद। इत्युपनिषत्॥१४॥

In Public domain. Digitization Muthulakshmi Research Academy

ॐ भद्रं कर्णेभिः शृणुयाम देवाः। भद्रं पश्येमाक्ष-भिर्यजत्राः। स्थिरैरङ्गैस्तुष्टुवाꣳसस्तनूभिः। व्यशेम देवहितं यदायुः। स्वस्ति न इन्द्रो वृद्धश्रवाः। स्वस्ति नः पूषा विश्ववेदाः। स्वस्ति नस्तार्क्ष्यो अरिष्टनेमिः। स्वस्ति नो बृहस्पतिर्दधातु॥

सह नाववतु। सह नौ भुनक्तु। सह वीर्यं करवावहै। तेजस्विनावधीतमस्तु मा विद्विषावहै॥

ॐ शान्तिः शान्तिः शान्तिः॥

॥ अनुज्ञा ॥

ध्रुवं ते राजा वरुणो ध्रुवं देवो बृहस्पतिः।
ध्रुवं त इन्द्रश्चाग्निश्च राष्ट्रं धारयतां ध्रुवम्॥

देवीं वाचमजनयन्त देवाः। तांविश्वरूपाः पशवो वदन्ति। सानो मन्द्रेषुमूर्जन्दुहाना। धेनुर्वागस्मानुप सुष्टुतैतु॥

पर्वत इवाविचाचलिः। इन्द्र इवेह दध्रुवस्तिष्ठ। इह राष्ट्रमुधारय। अभितिष्ठ पृतन्यतः। अधरे सन्तु शत्रवः। इन्द्र इव वृत्रहा तिष्ठ। सुमुहूर्तोऽस्तु। सुप्रतिष्ठितमस्तु॥ ऋद्ध्यास्म हव्यैर्नम सोपसद्यं। मित्रं देवं मित्रधेयन्नो अस्तु। अनूराधान् हविषा वर्द्धयन्तः। शतं जीवेम शरदः सवीराः॥ दीर्घायुष्य-मस्तु।

हरिः ओं॥

नमो महद्भ्यो नमो अर्भकेभ्यो, नमो युवभ्यो नम आसीनेभ्यः।

यजाम देवान् यदि शक्नवाम मा ज्यायसः शंस मावृक्षि देवाः॥

In Public domain. Digitization Muthulakshmi Research Academy

ॐ नमस्सदसे नमस्सदसस्पतये नमस्सखीनां पुरोगाणां चक्षुषे नमो दिवे नमः पृथिव्यै॥

सदसस्पतिमद्भुतं प्रियमिन्द्रस्य काम्यम्।

सनिं मेधामयासिषम्॥

सर्वेभ्यो ब्राह्मणेभ्यो नमः॥

अशेषे हे परिषद् भवत्पादमूले मया समर्पितां इमां सौवर्णी दक्षिणां यत्किंचित् दक्षिणामपि यथोक्त दक्षिणामिव तांबूलं च स्वीकृत्य।

सर्वेषां महाजनानां क्षेमस्थैर्य धैर्य वीर्य विजय आयुरारोग्य ऐश्वर्याणां अहरहरभिवृद्ध्यर्थं, धन कनक वस्तु वाहनादि अष्टैश्वर्य समृद्ध्यर्थं, आयुष्मत् सत्सन्तान प्राप्त्यर्थं, सर्वमङ्गल प्राप्त्यर्थं, सर्वारिष्ट शान्त्यर्थं, सर्वाभीष्ट सिद्ध्यर्थं, परकृत मन्त्र यन्त्र तन्त्र आभिचार विषचूर्णादि विभेदनार्थं, भूतादि ग्रह निवृत्त्यर्थं, सर्वापच्छान्ति पूर्वक दीर्घायुर्विपुल धन सन्तति वृद्धि स्थिर लक्ष्मी शत्रु पराजयादि सदभीष्ट सिद्ध्यर्थं, आदित्यात्मक श्री महादेवादि प्रसाद सिद्ध्यर्थं, (श्री रुद्रैकादशिन्याख्य/श्री महारुद्राख्य/अतिरुद्राख्य) महा प्रायश्चित्त शुभ कर्म, महार्णवोक्त रीत्या प्राच्योदीच्याङ्ग गोदान नान्दीश्राद्ध वैष्णव श्राद्ध दश दानादिभिः वसोर्धारया च सहितं कर्तुं योग्यता सिद्धिं अनुगृहाण॥

★★★

In Public domain. Digitization Muthulakshmi Research Academy

।। विघ्नेश्वर पूजा ।।

शुक्लां ★ शान्तये।। ओं भूः ★ भूर्भुवस्सुवरोम्।।

ममोपात्त ★ प्रीत्यर्थं, तदेव लग्नं सुदिनं तदेव, ताराबलं चन्द्रबलं तदेव, विद्याबलं दैवबलं तदेव, लक्ष्मीपतेः अङ्घ्रियुगं स्मरामि। करिष्यमाणस्य कर्मणः निर्विघ्नेन परिसमाप्त्यर्थं आदौ श्री महागणपति पूजां करिष्ये।। (अप उपस्पृश्य।।)

गणानाँ त्वा गणपति ँ हवामहे कविं कवीनामुपम-श्रवस्तमम्। ज्येष्ठराजं ब्रह्मणां ब्रह्मणस्पत आनः शृण्वन्-नूतिभिस्सीद सादनम्।। अस्मिन् हरिद्रा बिम्बे सुमुखं श्री महा-गणपतिं ध्यायामि। श्री महागणपतिमावाहयामि।। श्री महागणपतये नमः आसनार्थं अक्षतान् समर्पयामि।।

पाद्यं समर्पयामि।
अर्घ्यं समर्पयामि।
आचमनीयं समर्पयामि।
स्नपयामि।
स्नानानन्तरं आचमनीयं समर्पयामि।
वस्त्रोत्तरीयार्थं अक्षतान् समर्पयामि।
उपवीताभरणार्थं अक्षतान् समर्पयामि।
दिव्य परिमल गन्धान् धारयामि।
हरिद्रा चूर्णं, कुङ्कुमं समर्पयामि।
शोभनाक्षतान् समर्पयामि।
पुष्पमालां समर्पयामि।
पुष्पैः पूजयामि।।

In Public domain. Digitization Muthulakshmi Research Academy

ॐ सुमुखाय नमः
ॐ एकदन्ताय नमः
ॐ कपिलाय नमः
ॐ गजकर्णकाय नमः
ॐ लम्बोदराय नमः
ॐ विकटाय नमः
ॐ विघ्नराजाय नमः
ॐ गणाधिपाय नमः
ॐ धूमकेतवे नमः
ॐ गणाध्यक्षाय नमः
ॐ फालचन्द्राय नमः
ॐ गजाननाय नमः
ॐ वक्रतुण्डाय नमः
ॐ शूर्पकर्णाय नमः
ॐ हेरम्बाय नमः
ॐ स्कन्द पूर्वजाय नमः
ॐ गणञ्जयाय नमः
ॐ गणपतये नमः
ॐ हेरम्बाय नमः
ॐ धरणी धराय नमः
ॐ महागणपतये नमः
ॐ लक्ष्य प्रदाय नमः
ॐ क्षिप्रप्रसादनाय नमः
ॐ अमोघ सिद्धये नमः
ॐ अमृताय नमः
ॐ मन्त्राय नमः
ॐ चिन्तामणये नमः
ॐ निधये नमः
ॐ सुमङ्गलाय नमः
ॐ बीजाय नमः
ॐ आशापूरकाय नमः
ॐ वरदाय नमः
ॐ शिवाय नमः
ॐ काश्यपाय नमः
ॐ नन्दनाय नमः
ॐ वाचा सिद्धाय नमः
ॐ ढुण्ढि विनायकाय नमः।

नाना विध परिमळ पत्र पुष्पाणि समर्पयामि।
ओं धूपदीपार्थं अक्षतान् समर्पयामि॥
ओं धूपदीपानन्तरं आचमनीयं समर्पयामि॥

❖ नैवेद्यं—ओं भूर्भुवस्सुवः। तत्सवितुर्वरेण्यं भर्गो देवस्य धीमहि। धियो योनः प्रचोदयात्। देव सवितः प्रसुव। सत्यं त्वर्तेन परिषिञ्चामि। अमृतोपस्तरणमसि।

In Public domain. Digitization Muthulakshmi Research Academy

ओं प्राणाय स्वाहा, अपानाय स्वाहा, व्यानाय स्वाहा, उदानाय स्वाहा, समानाय स्वाहा, ब्रह्मणे स्वाहा, श्रीमहागणपतये नमः, नालिकेर खण्डद्वयं कदली फलं निवेदयामि। अमृतापिधानमसि ॥ निवेदनानन्तरं आचमनीयं समर्पयामि।

पूगीफल समायुक्तं नागवल्ली दलैर्युतम्।
कर्पूर चूर्ण संयुक्तं तांबूलं प्रति गृह्यताम्।
श्रीमहा गणपतये नमः, कर्पूर तांबूलं समर्पयामि।

❖ कर्पूर नीराजनम्—ओं नमो व्रातपतये नमो गणपतये नमः प्रमथपतये नमस्ते अस्तु लंबोदराय एकदन्ताय विघ्नविनाशिने शिवसुताय श्री वरद मूर्तये नमो नमः ॥ कर्पूर नीराजनं दर्शयामि ॥ नीराजनानन्तरं आचमनीयं समर्पयामि ॥

मन्त्र पुष्पं समर्पयामि। स्वर्णपुष्पं समर्पयामि। समस्तोपचारान् समर्पयामि।

वक्रतुण्ड महाकाय सूर्यकोटि समप्रभ।
अविघ्नं कुरुमे देव सर्व कार्येषु सर्वदा ॥

॥ संकल्पः ॥

दर्भेष्वासीनः दर्भान् धारयमाणः। पत्न्यासह।

शुक्लाम्बरधरं विष्णुं शशिवर्णम् चतुर्भुजम्। प्रसन्नवदनम् ध्यायेत् सर्व विघ्नोपशान्तये।

ओं भूः .... भूर्भुवस्सुवरोम् ॥ ममोपात्तसमस्त-दुरितक्षयद्धारा श्रीपरमेश्वरप्रीत्यर्थं शुभे शोभने मुहूर्ते अद्यब्रह्मणः द्वितीयपरार्धे श्वेतवराहकल्पे वैवस्वतमन्वन्तरे अष्टाविंशतितमे कलियुगे प्रथमे पादे जम्बूद्वीपे भारतवर्षे भरतखंडे मेरोः दक्षिणे

In Public domain. Digitization Muthulakshmi Research Academy

पार्श्वे (विन्ध्यस्य उत्तरे आर्यावर्तैकदेशे इन्द्रप्रस्थमहाक्षेत्रे दक्षिणवाहिन्याः यमुनायाः पश्चिमे तीरे) विक्रमशके बौद्धावतारे प्रभवादीनां षष्ट्याः संवत्सराणां मध्ये बार्हस्पत्यमानेन........ नाम संवत्सरे, सौरचान्द्रमानाभ्यां............ नामसंवत्सरे दक्षिणायने/ उत्तरायणे.... ऋतौ.... मासे शुक्लपक्षे/कृष्णपक्षे शुभतिथौ....... वासरयुक्तायां................. नक्षत्रयुक्तायां शुभयोगशुभकरण एवंगुणविशेषणविशिष्टायां अस्यां वर्तमानायां........ शुभतिथौ आसेतु हिमाचल अन्तर्वर्तिनां सर्वेषां महाजनानां एतद्देश-प्रसूतानां महाजनानां विद्या ग्रहणार्थं उद्योगार्थं च अन्य देशवासिनां माणवकानां बालिकानां च वेदोक्त पूर्णायु रभिवृद्ध्यर्थं, सर्व मंगलावाप्त्यर्थं, विशिष्य (श्रविष्ठा नक्षत्रे कुंभ राशौ आविर्भूतानां) श्रीमत् जयेन्द्र सरस्वती संयमीन्द्राणां, (उत्तराषाढ़ा नक्षत्रे मकर राशौ आविर्भूतानां) श्रीमत् शंकर विजयेन्द्र सरस्वती संयमीन्द्राणां अस्मदाचार्य पादानां, (मृगशिरो नक्षत्रे मिथुन राशौ आविर्भूतानां) श्री भारती तीर्थ महास्वामिनां शृंगगिरि निवासिनां जगद्गुरूणां आचार्य पादानां परमानुग्रहसिद्ध्यर्थं, सर्वेषां भारतीयानां महाजनानां कृत्तिकादि अपभरण्यन्तेषु अष्टा विंशति नक्षत्रेषु, मेषादि मीन पर्यन्तेषु द्वादश राशिषु जातानां शुभ नामधेयानां विनायकादि समस्त हरिहर देवता प्रसादेन वेदोक्त पूर्णायुषः अभिवृद्ध्यर्थं, अरोग दृढ़ गात्रता सिद्ध्यर्थं, देशेऽस्मिन् क्षाम क्षोभ निवृत्ति द्वारा सुवृष्ट्या सस्याभिवृद्ध्यर्थं, वापी कूप तटाकादिषु जल परिपूर्णता सिद्ध्यर्थं, अपौरुषेय वेद वचसां यथा नियमं अभिवृद्ध्यर्थं, वेदाऽभिवृद्ध्यर्थं, वेद विदामभिवृद्ध्यर्थं, वेद वित्सु ब्राह्मणेषु श्रद्धा भक्ति अतिशय सिद्ध्यर्थं, राज्ञां स्व

In Public domain. Digitization Muthulakshmi Research Academy

धर्म परिपालने प्रवृत्ति सिद्ध्यर्थं, अमात्य वर्गाणां मध्ये परस्परं वैमनस्य निवृत्तिद्वारा सौमनस्य सिद्ध्यर्थं, भारत देशस्य सीमासु देश संरक्षणार्थं अहोरात्रे जागरूकतया देश संरक्षणं कुर्वतां भटानां कायिक मानसिक धैर्य सिद्ध्यर्थं, बाहुबल सिद्ध्यर्थं, अन्यदेशीयैः अप्रति धृष्णुत्व सिद्ध्यर्थं, धेनूनां क्षीर समृद्ध्यर्थं, स्त्रीणां युवतीनां कन्यकानां सौन्दर्य सौशील्यादि शोभन गुणाभिवृद्ध्यर्थं, उद्वाहार्थं विद्यमानानां कुमाराणां कन्यकानां सत्कुलात् स्व वर्णे एव अनुरूप कन्या प्राप्तिमूलं अनुरूप वर प्राप्तिमूलं उद्वाह मंगल प्राप्त्यर्थं, विद्यार्थिनां विद्या मेधा प्रज्ञा प्रतिभाऽभिवृद्ध्यर्थं, उद्योगे विद्यमानानां उपर्युपरि उन्नत स्थान प्राप्ति द्वारा विशेष कीर्ति लाभाऽभिवृद्ध्यर्थं, इदानीं असकृत् परिदृश्यमान भूकम्पन भूमिभेदन अग्निदाह वायु प्रकोप अतिवृष्टि अनावृष्ट्यादि प्रयुक्त सकल विध उत्पात निवृत्त्यर्थं, बहु संघात मरण निवृत्त्यर्थं, लोककल्याण सिद्ध्यर्थं, सर्वेषां महाजनानां क्षेम स्थैर्य धैर्य वीर्य विजय आयुरारोग्य ऐश्वर्याणां अभिवृद्ध्यर्थं, आयुष्मत् सत्सन्तान समृद्ध्यर्थं, समस्त मंगलावाप्त्यर्थं... ॥

सर्वेषां महा जनानां जन्माभ्यासात् जन्म प्रभृति एतत्क्षण पर्यन्तं बाल्ये वयसि कौमारे यौवने वार्धके च जाग्रत् स्वप्न सुषुप्त्यवस्थासु काम-क्रोध-लोभ-मोह-मद-मात्सर्यादिभिः मनो व्यापारैः श्रवण स्पर्शन दर्शन रसन घ्राणनैः श्रोत्र त्वक् चक्षुः जिह्वा नासिकाख्य ज्ञानेन्द्रिय व्यापारैः वचनादान विहरणोत्सर्ग आनन्दनैः वाक्पाणि पाद पायूपस्थाख्य कर्मेन्द्रिय व्यापारैश्च संभावितानां; ब्रह्महत्या सुरापान स्वर्णस्तेय गुरुतल्पगमन तत्

In Public domain. Digitization Muthulakshmi Research Academy

संसर्गाख्य पञ्च महा पातकानां; गर्भहनन गोवध शिवलिंग चालनादीनां अतिपातकानां; गुर्वधिक्षेप वेद निन्दा नराश्व रजत भूमि वज्र मणि स्त्री गो शतपल ताम्र निक्षेप हरणादीनां समपातकानां; मातृ पितृ गुरु त्याग तटाक आराम विक्रय आत्मार्थ पाक क्रियारम्भ सदा परान्न भोजन असच्छास्त्राभ्यास परवृत्ति छेदनादीनां उप पातकानां; खराश्व उष्ट्र मृग इभ अश्वादि मीन-सर्प-महिष-वधादीनां संकलीकरणानां; कृमि कीट पक्षि जलचर वध फलकाष्ठ कुसुमस्तेयादीनां मलिनीकरणानां; निन्दित धनादान कुसीद जीवन असत्य भाषणादीनां अपात्री करणानां; मद्याद्यनाघ्रेय पदार्थाघ्राण जिह्मत्वादीनां जाति भ्रंशकराणां; नग्न स्नान जनकादि एक वचनान्त युष्मच्छब्द प्रयोग अस्नान भोजनादीनां प्रकीर्णकानां; एवं नवानां नवविधानां बहूनां बहुविधानां; ज्ञानतः सकृत्कृतानां, अज्ञानतः असकृत्कृतानां, ज्ञानतः अज्ञानतश्च अभ्यस्तानां, निरन्तरा-भ्यस्तानां, चिरकालाभ्यस्तानां, सर्वेषां पापानां सद्यः अपनोदनार्थं;

सर्वेषां महा जनानां जन्मनक्षत्र जन्मराशि वशात्, नाम नक्षत्र नाम राशि वशात्, जन्मानुजन्म त्रिजन्म होरा-द्रेक्काण-नवांश-द्वादशांश-त्रिंशांश-षष्ट्यंश-भावांश-अष्टवर्ग चक्र वशात्, सांघातिक सामुदायिक ग्रह उपग्रह भावग्रह अरिष्टग्रह मारक-ग्रह क्रूर-ग्रह क्षान्ति-ग्रह क्षणिक-ग्रह संयोग वीक्षण अर्धपात दृष्टि लत्ता वध वैनाशिक प्रत्यर व्यय षड्वर्गज रूप देह भावज वशात्, द्यून रिष्फारिष्ट अष्टम मारक नीच स्थान स्थितानां, मान्दि धूमकेत्वादि उपग्रह सहितानां, आदित्यादीनां नवानां ग्रहाणां मध्ये

In Public domain. Digitization Muthulakshmi Research Academy

ये ये दुस्थानाधिपत्य दुष्ट ग्रह योगादि प्रयुक्त पाप दुष्टाः ये च निसर्गतः पापाः तेषामानुकूल्य सिद्ध्यर्थं, शरीर वाक् कुटुंब बुद्धि कामायुर्भाव भाग्य धर्म कर्मायादि शुभस्थान स्थितानां, निसर्गतः शुभ राजयोगादि फलप्रदानां शुभानां ग्रहाणां अत्यन्तातिशय शुभफल प्रदातृत्व सिद्ध्यर्थं, प्रारब्ध कर्म वशात् अवश्यानु भाव्यतया प्राप्तानां परकृत क्रियमाण करिष्यमाण सकल मन्त्र तन्त्र यंत्र विषचूर्ण आभिचार कृत्याञ्जनादि प्रेरित आध्यात्मिक आधि दैविक आधि भौतिक अतर्कि तापत्प्रद व्याधीनां आत्मात्मीय पीड़ा चिन्तन दर्शनादि जनितानां अन्ततः निवृत्ति द्वारा क्षिप्रारोग्य मनः प्रसाद कुटुंब-वृद्धि परम स्वास्थ्यादि सिद्ध्यर्थं;

श्रुति स्मृति इतिहास पुराण प्रसिद्धानां "किं जप्येन अमृतत्वं नो ब्रूहि" इति मोक्षसाधन जप्य प्रश्ने "एतानि हवा अमृतस्य नामधेयानि एतेर्हवा अमृतो भवति" इति प्राधान्येन मोक्षसाधन-त्वेन जाबालोपनिषत् प्रति पादितानां, "शतशाखा गतं साक्षाच्छत रुद्रीय मुत्तमम्। तस्मा त्तज्जप मात्रेण सर्व पापैः प्रमुच्यते" इति स्कान्दान्तर्गत सूत-संहिता वचनावगत सर्व पापापनोदकत्वानां, "एक शतं यजुश्शाखाः तासु रुद्रोपनिषदाम्नायते" इति सर्व शाखा विराजमानत्वेन भट्टभास्करादिभिः संस्तुतानां पूर्वोक्त जाबालोपनिषत्प्रश्न प्रतिवचनाभ्यां मोक्ष साधन, जप्योपनिषदन्त-रापेक्षया उत्कृष्टत्वे "तदा प्राह महादेवः राजानं प्रीतमानसः। इमानि मे रहस्यानि नामानि श‍ृणुचानघ। सर्व वेदेषु गीतानि संसार शमनानि च! नमस्कुरुष्व सततं एभिर्नाम पदैः शुचिः॥ अध्यायं शतरुद्रीयं यजुषां सारमुत्तमम्। जपस्वानन्य चेतस्कः मय्येवासक्त

In Public domain. Digitization Muthulakshmi Research Academy

मानसः॥ ब्रह्मचारी मिताहारः ब्रह्मनिष्ठस्समाहितः। जपेदामरणाद्रुद्रं स याति परमां गतिम्॥'' इति सर्व संसार दुःख मोचक परमशिव नाम निकुरुंब करंबितत्वेन तादृश नमस्कार करंबितत्वेन च परमगति प्रापकत्वादस्य रुद्राध्यायस्य न केवलं यजुस्सारत्वं अपितु सर्ववेदोत्त-मत्वमिति कूर्म पुराणोद्घोषितानां, ''यः शत रुद्रीय मधीते सोग्नि पूतो भवति, सुरापानात्पूतो भवति, ब्रह्महत्यायाः पूतो भवति, स्वर्णस्तेयात्पूतो भवति, तस्मादविमुक्त माश्रितो भवति, अत्याश्रमी सर्वदा सकृद्वा जपेत् अनेन ज्ञान माप्नोति संसारार्णव नाशनं'' इति कैवल्योपनिषदि ब्रह्महत्यादि महापातक कृत्यवदाचरित अकृत्यादि सर्व पाप निबर्हणत्वेन संसारार्णव नाशन आत्मज्ञान प्रधान साधनत्वेन च निर्दिष्टानां, ''सर्गात्पुरानिरालोके यदेत न्निष्कलं परम्! चिदानन्दमयं ज्योति स्स आत्मा केवल शिवः॥ स एवादौ रजो रूपं सृष्ट्वा ब्रह्माण मात्मनः। सृष्टिकर्म नियुक्ताय तस्मै वेदांश्च दत्तवान्॥ स एष मुनिभिः पूर्वैः मरीच्यत्रि पुरोगमैः। सह देवैः धृतस्तेभ्यः तच्छिष्या जगृहुश्शतम्॥ एषवः परमो मन्त्रः एषवः परमं तपः। रुद्राध्याय जपः पुंसां परं कैवल्य साधनम्। ये महापातकै र्युक्ता उप पातकिनश्च ये। रुद्राध्याय जपात्सद्यः तेपि यान्ति परांगतिम्॥'' इति सृष्ट्यादौ श्री परमेश्वर मुखारविन्द निर्गतत्वेन, ब्रह्म मरी च्यत्रि प्रमुख मुनिवर परंपरागतत्वेन परम मन्त्रत्वेन परम तपस्त्वेन सर्वोपनिषत्सारत्वेन च ब्रह्मोत्तर खण्ड घण्टा घोषितानां, ''रुद्राध्याये भुवं प्राप्ते साक्षात् कैवल्य साधने। भीताः प्रदुद्रुवुः सर्वे ते वै पातक नायकाः॥ यमे विज्ञापयामासुः सहतैश्चोप पातकैः। नरकस्य विवृद्ध्यर्थं साधिकारास्त्वया कृताः॥ अधुना

In Public domain. Digitization Muthulakshmi Research Academy

वर्तितुं लोके न शक्तास्म स्वयं प्रभो। रुद्रजाप्य प्रभावेन निर्दग्धाश्चैव विद्रुताः॥ ग्रामे ग्रामे नदी तीरे पुण्येष्वायतनेषु च! रुद्र जाप्येन पर्याप्ते कथं परिचरे महि॥ प्रायश्चित्त सहस्त्रं वा गणयामो न किञ्चन! रुद्र जाप्यं क्षणेनापि सोढुं शक्ता वयं न च॥ महापातक मुख्यानां अस्माकं सोप जीविनाम्! रुद्र जाप्यं परं घोरं रुद्र जाप्यं महद्विषम्॥" इति निखिल पातक प्रायश्चित्तत्वेन स्व लोक परिपूरणकाम यम प्रेरित महापातकोप पातकरूप किंकर पलायनात्मक परि भव जनकत्वेन यम भटाऽसह्य वेदनोत्पादकत्वेन इतर निखिल प्रायश्चित्तादप्युत्तमत्वेन च तत्र तत्र उपवर्णितानां, "वेदमेक गुणं जप्त्वा तदह्नैव विशुद्ध्यति। रुद्रैकादशिनीं जप्त्वा तत्क्षणादेव शुद्ध्यति!! वृक्षस्य मूल सेकेन शाखाः पुष्यन्ति वै यथा। शिवे रुद्र जपात्प्रीते प्रीता एवास्य देवताः। अतो रुद्र जपादेव भुक्तिमुक्ती प्रसिद्ध्यतः॥" इति सूत संहिता वचनेन, "शत रुद्रान् जपेद्यस्तु ध्याय मानो महेश्वरम्। यश्च सागर पर्यन्तां स शैल वन काननाम्!! दद्यात् काञ्चन संयुक्तां भूमिमोषधि संयुताम्। तस्मादप्यधिकं तस्य सकृद्रुद्र जपाद्भवेत्।" इति शैवपुराण वचनेन, "सर्वोपनिषदां सारो रुद्राध्यायः समर्थितः!" "भोगार्थिनो मुमुक्षोर्वा प्रायश्चित्तार्थिनोपि वा!! रुद्रोपनिषदं मुक्त्वा गतिरन्या न विद्यते! प्रयतः प्रातरुत्थाय यदधीते विशांपते॥ प्राञ्जलिः शत रुद्रीयं नास्य किञ्चन दुर्लभम्॥" इत्यादि महाभारत वचनेन च सर्व किल्बिष मोचकत्वेन जपक्षण एव शुद्धि जनकत्वेन समस्त देवता प्रीति निष्पादकत्वेन भुक्ति मुक्ति प्रसाधकत्वेन अखण्ड भूमण्डल दान पुण्याधिक पुण्य प्रदत्वेन दुर्लभ समस्त वस्तु प्रापकत्वेन च

In Public domain. Digitization Muthulakshmi Research Academy

निर्णीतानां, आदितो नमस्कार, अन्ततो नमस्कार, उभयतो नमस्कार, एकोन सप्तत्युत्तर शत संख्याक महा-मन्त्रात्मकानां आपस्तंब सूत्रकार पठित यज्ञ संयुक्त कल्पेषु महाग्नि चयनांग होमे विनियुक्तानामपि जाबाल मान्धातृ शौनक सायणाचार्य वसिष्ठ याज्ञवल्क्य अत्रि अङ्गिरसः प्रमुखै र्विरचितेषु अयज्ञ संयुक्त कल्पेष्वपि धर्मार्थ काम मोक्षादि समस्त ऐहिकाऽऽमुष्मिक पुरुषार्थ साधकत्वेन प्रख्यापितानां, महाभारत स्कान्द वाय्वादि महापुराणेषु पुत्र पशु विद्यैश्वर्य प्रदत्वेन मुहु र्मुहु रुद्धोषितानां, तैत्तिरीय कृष्ण यजु श्शाखा मध्यगत अग्निकाण्ड मध्यवर्तिनां चतुर्वेद सार भूतानां श्रीमत् पञ्चाक्षर महामन्त्र गर्भितानां श्री रुद्र मन्त्राणां त्रेधाविभाग, षोढाविभाग, षोडशधा विभाग, अष्टाचत्वारिंशद्धा विभाग, एकोन सप्तत्यधिक शतधा विभागात्मकेषु पक्षेषु अष्टा चत्वारिंशद्धा विभाग पक्ष माश्रित्य दशांश होम विधानेन एभिः ब्राह्मणै स्सह आचार्य मुखेन महार्णवोक्त रीत्या प्राच्योदीच्याङ्ग गोदान, नान्दी श्राद्ध, वैष्णव श्राद्ध, दशदानादिभिः सह वसोर्द्धारया च सह (महा रुद्राख्य/ रुद्रैकादशिन्याख्य/अतिरुद्राख्य) महा प्रायश्चित्त शुभ कर्म करिष्ये॥

मया संकल्पित (श्रीमहारुद्राख्य/रुद्रैकादशिन्याख़्य/ अतिरुद्राख़्य) शुभकर्म आरंभ मुहूर्त लग्नापेक्षया आदित्यादीनां नवानां ग्रहाणामानुकूल्य सिद्ध्यर्थं ग्रहप्रीतिदानं च करिष्ये॥ दर्भान् उत्तरतः निरस्य, अप उपस्पृश्य, गणानां त्वेति मन्त्रेण महा गणपतिं उद्वास्य॥

★★★

In Public domain. Digitization Muthulakshmi Research Academy

॥ ग्रहप्रीतिः ॥

हिरण्यगर्भ गर्भस्थं हेमबीजं विभावसोः।
अनन्त पुण्य फलदं अतश्शांन्तिं प्रयच्छमे॥

इदं हिरण्यं सदक्षिणाकं सतांबूलं आदित्यादीनां नवानां ग्रहाणां आनुकूल्य सिद्ध्यर्थं नाना गोत्रेभ्यः ब्राह्मणेभ्यः संप्रददे। नमम॥

॥ गोदानम् ॥

हिरण्य गर्भ गर्भस्थं हेमबीजं विभावसोः।
अनन्त पुण्य फलदं अतश्शान्तिं प्रयच्छमे॥
यज्ञ साधन भूतायाः विश्वस्य अघ प्रणाशिनी।
विश्वरूप धरोदेवः प्रीयतां अनया गवा॥
गवामङ्गेषु तिष्ठन्ति भुवनानि चतुर्दश।
तस्मादस्य प्रदानेन अतश्शान्तिं प्रयच्छमे॥

मया संकल्पित (श्री रुद्रैकादशिन्याख्य/महारुद्राख्य/ अतिरुद्राख्य) महाप्रायश्चित्त शुभकर्म पूर्वांगत्वेन विहित गोदान प्रत्याम्नायत्वेन इदं नारिकेल पूर्णफलं सदक्षिणाकं सतांबूलं आदित्यात्मक श्रीरुद्र प्रीतिं कामयमानः तुभ्यमहं संप्रददे। न मम।

॥ नान्दी श्राद्धम् ॥

हिरण्य गर्भ गर्भस्थं हेमबीजं विभावसोः।
अनन्त पुण्य फलदं अतश्शान्तिं प्रयच्छमे॥

मया संकल्पित (श्री रुद्रैकादशिन्याख़्य/महारुद्राख़्य/ अतिरुद्राख़्य) महाप्रायश्चित्त शुभकर्माङ्गभूते अस्मिन् आभ्युदयिके

In Public domain. Digitization Muthulakshmi Research Academy

सत्यवसु संज्ञकानां विश्वेषां देवानां नान्दीमुखानां तृप्त्यर्थं, ये ये विहिताः या या विहिताश्च तेषां तेषां तासां तासां नान्दीमुखानां तृप्त्यर्थं, अभ्युदय संरक्षक महाविष्णोश्च तृप्त्यर्थं, इमानि हिरण्यानि सदक्षिणाकानि सतांबूलानि नाना गोत्रेभ्यः ब्राह्मणेभ्यः तेभ्यः तेभ्यः संप्रददे। न मम॥ मया हिरण्येन कृतं आभ्युदयिकं संपन्नम्। इडादेवहूः मनुर्यज्ञनीर्बृहस्पतिं रुक्था मदानि शꣳसिषद्विश्वे देवास्सूक्तवाचः पृथिवि मातर्मा मा हिꣳसीर्मधु मनिष्ये मधु जनिष्ये मधुवक्ष्यामि मधु वदिष्यामि मधुमतीं देवेभ्यो वाचमुद्यासꣳ शुश्रूषेण्यां मनुष्येभ्यस्तं मा देवा अवन्तु शोभायै पितरोऽनु मदन्तु। इड एहिं, अदित एहिं, सरस्वत्येहिं, शोभनं शोभनम्। मनः समाधीयताम्। (समाहितमनसः स्मः॥) प्रसीदन्तु भवन्तः। (प्रसन्नाः स्मः॥) श्रीरस्त्विति भवन्तो ब्रुवन्तु। (अस्तु श्रीः॥) पुण्याहं भवन्तो ब्रुवन्तु। (पुण्याहम्॥)

॥ वैष्णव श्राद्धम् ॥

हिरण्य गर्भ गर्भस्थं हेमबीजं विभावसोः।
अनन्त पुण्य फलदं अतश्शान्तिं प्रयच्छमे॥

मया संकल्पित (श्री रुद्रैकादशिन्याख्य/महारुद्राख्य/अतिरुद्राख्य) महा प्रायश्चित्त शुभकर्मणि केशव, नारायण, माधव, गोविन्द, विष्णु, मधुसूदन, त्रिविक्रम, वामन, श्रीधर, हृषीकेश, पद्मनाभ, दामोदराणां (इति शुक्लपक्षे) (कृष्णपक्षे तु—सङ्कर्षण, वासुदेव, प्रद्युम्न, अनिरुद्ध, पुरुषोत्तम, अधोक्षज, नारसिंह, अच्युत, जनार्दन, उपेन्द्र, हरि, श्रीकृष्णानां) तृप्त्यर्थं इदं हिरण्यं सदक्षिणाकं सतांबूलं नानागोत्रेभ्यः ब्राह्मणेभ्यः तेभ्यः तेभ्यः संप्रददे। न मम।

In Public domain. Digitization Muthulakshmi Research Academy

॥ पूतत्व कृच्छ्रम् ॥

हिरण्यगर्भ गर्भस्थं हेमबीजं विभावसोः।
अनन्त पुण्य फलदं अतश्शान्तिं प्रयच्छमे॥

मया संकल्पित (श्री महारुद्राख्य/रुद्रैकादशिन्याख्य/अतिरुद्राख्य) शुभ कर्मणि पूतत्व सिद्ध्यर्थं प्राजापत्य कृच्छ्र प्रत्याम्नायं इदंहिरण्यं नानागोत्रेभ्यः ब्राह्मणेभ्यः संप्रददे। न मम॥

॥ दश दानम् ॥

हिरण्यगर्भ गर्भस्थं हेमबीजं विभावसोः।
अनन्त पुण्य फलदं अतश्शान्तिम् प्रयच्छमे॥

मया संकल्पित (श्री महारुद्राख्य/रुद्रैकादशिन्याख्य/अतिरुद्राख्य) शुभ कर्मणि पूर्वाङ्गत्वेन विहित गो, भू, तिल, हिरण्याज्य, वासो धान्य, गुळ, रौप्य, लवण दशदान प्रत्याम्नायं यथा शक्ति हिरण्यं नाना गोत्रेभ्यः ब्राह्मणेभ्यः संप्रददे। न मम॥

(१) गोदानं

गवामङ्गेषु तिष्ठन्ति भुवनानि चतुर्दश।
तस्मादयाः प्रदानेन अतः शान्तिं प्रयच्छमे॥
यज्ञसाधन भूताया विश्वस्य अघ प्रणाशिनी।
विश्वरूपधरो देवः प्रीयतामनया गवा॥

(२) भू दानम् (भोजन पर्याप्ता)

सर्वसस्याश्रया भूमिः वराहेण समुद्धृता।
अनन्त सस्य फलदा अतः शान्तिं प्रयच्छमे॥
(भू प्रतिनिधि चन्दन काष्ठम्)

In Public domain. Digitization Muthulakshmi Research Academy

(३) तिलदानं (द्रोण द्वयं)

तिलाः पापहरा नित्यं विष्णोर्देह समुद्भवाः।
तिलदानाद-सह्यं मे पापं नाशय केशव॥
तस्मादस्य प्रदानेन अतः शान्तिं प्रयच्छमे॥
(इमां तिलान्)॥

(४) हिरण्यदानं (निष्क त्रयं)

हिरण्य गर्भ गर्भस्थं हेम बीजं विभावसोः।
अनन्त पुण्य फलदं अतश्शान्ति प्रयच्छमे॥
(इदं हिरण्यं)

(५) आज्यदानं (आढ़क परिमाणं)

कामधेनु समुद्भूतं सर्व क्रतुषु संस्थितम्।
देवानामाज्य-माहारं अतश्शान्तिं प्रयच्छमे॥
(इदं आज्यं)

(६) वस्त्र दानं (द्वयं)

शीतवातोष्ण संत्राणं लज्जायाः रक्षणं परम्।
देहालंकरणं वस्त्रं अतश्शान्ति प्रयच्छमे॥ (इदं वस्त्रं)

(७) धान्य दानं (सार्धरवारी परिमाणं)

धन्यं करोषि दातारं इह लोके परत्र च।
प्राणिनां जीवनं धान्यं अतश्शान्तिं प्रयच्छमे॥
(इदं धान्यं)

(८) गुळ दानं (षष्टिपलम्)

इक्षु खण्ड समुद्भूतं सर्व प्राणिमनो हरम्।
सर्व पाप क्षयं तस्मात् अत श्शान्तिं प्रयच्छमे॥
(इदं गुळं)

In Public domain. Digitization Muthulakshmi Research Academy

(९) रौप्य दानं (निष्क चतुष्टम्)

रुद्र नेत्र समुद्भूतं रजतं पितृवल्लभम्।
पितृप्रीतिकरं नित्यं अतश्शान्तिं प्रयच्छमे॥ (इदं रजतं)

(१०) लवण दानं (सार्ध खारी)

रसानामग्रजं श्रेष्ठं लवणं बलवर्द्धनम्।
ब्रह्मणा निर्मितं साक्षात् अतश्शान्तिं प्रयच्छमे॥
(इदं लवणं)

॥ पञ्चदानं॥

उदकुंभं— ब्रह्मणा प्रथमं सृष्टाः अघमर्षण हेतवः।
आपोयुष्मत्प्रदानेन तृप्यन्तु ममदेवताः॥
(इदं उदकुंभं)

दीपं— परमात्म तनो दीप परमार्थ प्रकाशक।
आत्मानात्म विवेकं मे जनय त्वत्प्रसादतः॥
(इदं दीपं)

घण्टा— सर्व वाद्य मयी घण्टा सर्वाघौघ विनाशिनी।
तस्मादस्याः प्रदानेन अतश्शान्तिं प्रयच्छमे॥
(इमां घण्टां)

पुस्तकं— पञ्चाशत् वर्ण संयुक्तं पुस्तकं विमलाक्षरम्।
पुस्तकं संप्रयच्छामि प्रीता भवतु भारती॥
(इदं पुस्तकं)

वस्त्रदानं— शीतवातोष्ण सन्त्राणं लज्जायाः रक्षणं परम्।
देहालंकरणं वस्त्रं अतः शान्तिं प्रयच्छमे॥
(इदं वस्त्रं)

In Public domain. Digitization Muthulakshmi Research Academy

फलदानं— फलं मनोरथ फलं प्रददाति सदा नृणाम्।
पुत्र पौत्राभिवृद्ध्यर्थं श्रेयःपुष्टिं प्रयच्छमे॥

तांबूलदानं— तांबूलं श्रीकरं भद्रं ब्रह्म विष्णु शिवात्मकम्।
तस्मादस्य प्रदानेन अतश्शान्तिं प्रयच्छमे॥

॥ पुण्याहवाचनम् ॥

अद्य पूर्वोक्त एवं गुण विशेषण विशिष्टायां अस्यां..... शुभतिथौ मण्टपादि शुद्ध्यर्थं सर्वोपकरण शुद्ध्यर्थं अभ्युदय कर्मांगं च स्वस्ति पुण्याहवाचनं करिष्ये॥

ओं भूर्भुवस्सुवः। आपो वा इदं ँ सर्वं विश्वा भूतान्यापः प्राणावा आपः पशव आपोन्न मापोऽमृत मापः सम्राडापो विराडापः स्वराडापश्छन्दा ँ स्यापो ज्योती ँ ष्यापो यजू ँष्यापः सत्यमापः सर्वा देवता आपो भू भुंवस्सुवराप ओम्॥ इमं मे वरुण श्रुधीहवमद्याच मृड़य। त्वामवस्युराचके। तत्वायामि ब्रह्मणा वन्दमानस्तदाशास्ते यजमानो हविर्भिः। अहेडमानो वरुणेह बोध्युरु श ँसमान आयुः प्रमोषीः॥ ओं भूर्भुवस्सुवरों अस्मिन् कुंभे सकल तीर्थाधिपतिं वरुणं ध्यायामि।

वरुणं आवाहयामि।

वरुणाय नमः आसनं समर्पयामि।

वरुणाय नमः पाद्यं समर्पयामि।

वरुणाय नमः अर्घ्यं समर्पयामि।

वरुणाय नमः आचमनीयं समर्पयामि।

वरुणाय नमः स्नापयामि।

वरुणाय नमः स्नानानन्तरं आचमनीयं समर्पयामि।

In Public domain. Digitization Muthulakshmi Research Academy

वरुणाय नमः वस्त्रोत्तरीयं समर्पयामि।

वरुणाय नमः उपवीताऽऽभरणानि समर्पयामि।

वरुणाय नमः गन्धान् धारयामि।

वरुणाय नमः हरिद्रा कुंकुमं समर्पयामि।

वरुणाय नमः शोभनाऽक्षतान् समर्पयामि।

वरुणाय नमः पुष्पमालां समर्पयामि। पुष्पैः पूजयामि।

वरुणाय नमः

प्रचेतसे नमः

सुरूपिणे नमः

अपां पतये नमः

मकर वाहनाय नमः

जलाधिपतये नमः

पाश हस्ताय नमः

तीर्थ राजाय नमः

वरुणाय नमः नानाविध पत्र पुष्पाणि समर्पयामि। धूप दीपार्थं अक्षतान् समर्पयामि।

नैवेद्यं। ओं भूर्भुवस्सुवः। तत्सवितुर्वरेण्यं भर्गो देवस्य धीमहि। धियो योनः प्रचोदयात्। देव सवितः प्रसुव।

सत्यं त्वर्तेन परिषिञ्चामि। अमृतोपस्तरणमसि। प्राणाय स्वाहा, अपानाय स्वाहा, व्यानाय स्वाहा। उदानाय स्वाहा, समानाय स्वाहा, ब्रह्मणे स्वाहा। वरुणाय नमः कदली फलं निवेदयामि। अमृतापिधानमसि॥ निवेदनानन्तरं आचमनीयं समर्पयामि॥ पूगीफल समायुक्तं नागवल्ली दलैर्युतम्। कर्पूर चूर्ण संयुक्तं तांबूलं प्रतिगृह्यताम्॥ कर्पूर तांबूलं समर्पयामि।

In Public domain. Digitization Muthulakshmi Research Academy

समस्तोपचारान् समर्पयामि॥ अस्मिन् पुण्याहवाचन जप कर्मणि सर्वेभ्यो ब्राह्मणेभ्यो नमः॥ भवद्भिः अनुज्ञातः पुण्याहं वाचयिष्ये। (ओं वाच्यताम्)॥ कर्मणः पुण्याहं भवन्तो ब्रुवन्तु। (पुण्याहं कर्मणोस्तु)॥ अद्यकृत अभ्युदय कर्मणे स्वस्ति भवन्तो ब्रुवन्तु। (अभ्युदय कर्मणे स्वस्ति)॥

अभ्युदय कर्मणः ऋद्धिं भवन्तो ब्रुबन्तु। (कर्म ऋध्यतां)॥ आत्म शुद्धि कर्मणे, मण्टपादि सर्वोपकरण शुद्धि कर्मणे स्वस्ति भवन्तो ब्रुवन्तु। (कर्मणे स्वस्ति)॥ आत्म शुद्धि कर्मणः मण्टपादि सर्वोपकरण शुद्धि कर्मणश्च ऋद्धिं भवन्तो ब्रुवन्तु। (कर्म ऋध्यतां)॥ ऋद्धिः समृद्धिरस्तु। पुण्याहं समृद्धिरस्तु। शान्ति रस्तु। पुष्टिरस्तु। तुष्टिरस्तु। अविघ्नमस्तु। आयुष्यमस्तु। आरोग्य मस्तु। धन धान्य समृद्धिरस्तु। गो ब्राह्मणेभ्यः शुभं भवतु। ऐशान्यां बहिर्देशे अरिष्ट निरसन मस्तु। आग्नेय्यां यत्पापं तत्प्रतिहतमस्तु। सर्व शोभन मस्तु। सर्वाः संपदस्सन्तु॥

ओं शान्तिः शान्तिः शान्तिः।

॥ पवमान सूक्तम् ॥

दधिक्राव्णो अकारिषम्। जिष्णोरश्वस्य वाजिनः। सुरभि नो मुखाकरत्। प्रण आयूꣳषि तारिषत्॥ आपो हिष्ठा मयो भुवः। ता न ऊर्जे दधातन। महे रणाय चक्षसे। यो वः शिवतमो रसः। तस्य भाजयतेह नः। उशतीरिव मातरः। तस्मा अरं गमाम वः। यस्य क्षयाय जिन्वथ। आपो जनयथा च नः॥ ओं भुर्भुवस्सुवः॥

In Public domain. Digitization Muthulakshmi Research Academy

हिरण्यवर्णाः शुचयः पावका यासु जातः कश्यपो यास्विन्द्रः। अग्निं या गर्भं दधिरे विरूपास्तान आपश्शꣳ स्योना भवन्तु॥ यासाꣳ राजा वरुणो याति मध्ये सत्यानृते अवपश्य ञ्जनानाम्। मधुश्चुतश्शुचयो याः पावकास्ता न आपश्शꣳ स्योना भवन्तु॥ यासां देवा दिवि कृण्वन्ति भक्षं या अन्तरिक्षे बहुधा भवन्ति। याः पृथिवीं पयसोन्दन्ति शुक्रास्ता न आपश्शꣳ स्योना भवन्तु॥ शिवेन मा चक्षुषा पश्यतापश्शिवया तनुवोप स्पृशत त्वचं मे। सर्वाꣳ अग्नीꣳ रप्सुषदो हुवे वो मयि वर्चो बलमोजो निधत्त॥

पवमानस्सुवर्जनः। पवित्रेण विचर्षणिः। यः पोता स पुनातु मा। पुनन्तु मा देवजनाः। पुनन्तु मनवो धिया। पुनन्तु विश्व आयवः। जातवेदः पवित्रवत्। पवित्रेण पुनाहि मा। शुक्रेण देवदीद्यत्। अग्ने क्रत्वा क्रतूꣳ रनु॥१॥ यत्ते पवित्रमर्चिषि। अग्ने विततमन्तरा। ब्रह्म तेन पुनीमहे। उभाभ्यां देवसवितः। पवित्रेण सवेन च। इदं ब्रह्म पुनीमहे॥ वैश्वदेवी पुनती देव्यागात्। यस्यै बह्वीस्तनुवो वीतपृष्ठाः। तया मदन्तः सधमाद्येषु। वयꣳ स्याम पतयो रयीणाम्॥२॥ वैश्वानरो रश्मिभिर्मा पुनातु। वातः प्राणेनैषिरो मयो भूः। द्यावापृथिवी पयसा पयोभिः। ऋतावरी यज्ञिये मा पुनीताम्। बृहद्भिः सवितस्तृभिः। वर्षिष्ठै-र्देवमन्मभिः। अग्ने दक्षैः पुनाहि मा। येन देवा अपुनत। येनापो दिव्यंकशः। तेन दिव्येन ब्रह्मणा॥३॥ इदं ब्रह्म पुनीमहे। यः पावमानीरध्येति। ऋषिभिस्संभृतꣳ रसम्। स र्वꣳ स पूतमश्नाति। स्वदितं

In Public domain. Digitization Muthulakshmi Research Academy

मातरिश्वना। पावमानीर्यो अध्येति। ऋषिभिस्संभृतꣳ रसम्। तस्मै सरस्वती दुहे। क्षीरꣳ सर्पिर्मधूदकम्॥४॥ पावमानीस्स्वस्त्ययनीः। सुदुघाहि पयस्वतीः। ऋषिभिस्संभृतो रसः। ब्राह्मणेष्वमृतꣳ हितम्॥ पावमानीर्दिशन्तु नः। इमं लोकमथो अमुम्। कामान् समर्धयन्तु नः। देवीर्देवैःसमाभृताः। पावमानीस्स्वस्त्ययनीः। सुदुघाहि घृतश्चुतः। ऋषिभिः संभृतो रसः॥५॥ ब्राह्मणेष्वमृतꣳ हितम्। येन देवाः पवित्रेण। आत्मानं पुनते सदा। तेन सहस्रधारेण। पावमान्यः पुनन्तु मा। प्राजापत्यं पवित्रम्। शतोद्यामꣳ हिरण्मयम्। तेन ब्रह्म विदो वयम्। पूतं ब्रह्म पुनीमहे। इन्द्रस्सुनीती सहमा पुनातु। सोमस्स्वस्त्या वरुणस्समीच्या। यमो राजा प्रमृणाभिःपुनातु मा। जातवेदा मोर्जयन्त्या पुनातु। भूर्भुवस्सुवः॥६॥

तच्छं योरावृणीमहे। गातुं यज्ञाय। गातुं यज्ञपतये। दैवीस्स्वस्तिरस्तु नः। स्वस्तिर्मानुषेभ्यः। ऊर्ध्वं जिगातु भेषजम्। शन्नो अस्तु द्विपदे। शं चतुष्पदे। ओं शान्तिः शान्तिः शान्तिः॥७॥

ॐ जुंभकाय विद्महे पाशहस्ताय धीमहि। तन्नो वरुणः प्रचोदयात्॥

वरुणाय नमः सकलाराधनैः स्वर्चितम्॥

तत्वायामि ब्रह्मणा वन्दमानःतदाशास्ते यजमानो हविर्भिः। अहेडमानो वरुणेह बोध्यु रुशꣳसमान आयुः प्रमोषीः॥ अस्मात् कुंभात् आवाहितम् सकल तीर्थाधिपतिं वरुणं यथास्थानं प्रतिष्ठापयामि। कुंभ तीर्थेन मण्टपादीन् प्रोक्ष्य, प्राश्य॥

★★★

In Public domain. Digitization Muthulakshmi Research Academy

॥ आचार्य ऋत्विग् वरणम् ॥

संकल्पित (श्री महारुद्राख्य/रुद्रैकादशिन्याख्य/अति-रुद्राख्य) प्रायश्चित्त शुभकर्मणि सकल कर्म कर्तुं आचार्यं त्वां वृणे॥ (श्रीमहारुद्राख्य/ रुद्रैकादशिन्याख्य/अतिरुद्राख्य शुभ कर्मकुरुध्वम्॥) श्री सांब परमेश्वर पूजार्थं ऋत्विजं त्वां वृणे॥ (कलशादि पूजां कृत्वा, कुम्भस्थापनं कुर्यात्। तत्र मन्त्रः॥)

॥ कलश पूजा ॥

(कलशं गन्ध पुष्पाक्षतैरभ्यर्च्य।)
कलशस्य मुखे विष्णुः कण्ठे रुद्र समाश्रितः।
मूले तत्र स्थितो ब्रह्मा मध्ये मातृगणाः स्मृताः॥
कुक्षौ तु सागराः सर्वे सप्त द्वीपा वसुन्धरा।
ऋग्वेदोऽथ यजुर्वेदः सामवेदोऽप्यथर्वणः॥
अंगैश्च सहिताः सर्वे कलशांबु समाश्रिताः।
गंगेच यमुने चैव गोदावरि सरस्वति॥
नर्मदे सिन्धु कावेरि जलेऽस्मिन् सन्निधिं कुरु॥
आयान्तु देवपूजार्थं दुरितक्षय कारकाः।
(कलशोदकेन पूजोपकरणानि प्रोक्ष्य॥)

॥ शंख पूजा॥

शंखं चन्द्रार्क दैवत्यं कुक्षौ वरुण दैवतम्।
पृष्ठे प्रजापतिश्चैव अग्रे गंगा सरस्वती॥
त्रैलोक्ये यानि तीर्थानि वासुदेवस्य चाज्ञया।
शंखे तिष्ठन्ति विप्रेन्द्र तस्माच्छंखं प्रपूजयेत्॥

In Public domain. Digitization Muthulakshmi Research Academy

पाञ्चजन्याय विद्महे पवमानाय धीमहि। तन्नः शंखः प्रचोदयात्॥

अग्नेर्मन्वे प्रथमस्य प्रचेतसोयं पाञ्चजन्यं बहवः समिन्धते। विश्वस्यां विशि प्रविविशिवाꣳ समीमहे सनोमुञ्चत्वꣳहसः। (कलशे शंखोदकं पूरयित्वा गायत्र्या पुनः शंखं पूरयेत्॥)

घंटानादम् :- आगमार्थं तु देवानां गमनार्थं तु रक्षसाम्।
कुर्वे घंटारवं तत्र देवताह्वान लांछनम्॥
(इति घंटा नादं कुर्यात्)

॥ कलश आवाहनम् ॥

ब्रह्मजज्ञानं प्रथमं पुरस्ताद्विसीमतस्सुरुचो वेन आवः। सबुध्नियां उपमा अस्य विष्ठास्सतश्च योनिमसतश्च विवः॥ नाके सुपर्ण मुपयत्पतन्तꣳहृदा वेनन्तो अभ्यचक्षतत्वा। हिरण्यपक्षं वरुणस्य दूतं यमस्य योनौ शकुनं भुरण्युम्॥ आप्यायस्व समेतु ते विश्वतः सोम वृष्णियम्। भवा वाजस्य संगथे॥१॥ यो रुद्रो अग्नौ यो अप्सु य ओषधीषु यो रुद्रो विश्वा भुवनाऽऽविवेश तस्मै रुद्राय नमो अस्तु। (अप उपस्पृश्य)॥२॥

इदं विष्णुर्विचक्रमे त्रेधा निदधे पदम्। समूढमस्य-पाꣳसुरे॥ इन्द्रं विश्वा अवीवृधन्त्समुद्रव्यचसंगिरः। रथीतमꣳरथीनां वाजानाꣳ सत्पतिं पतिम्॥ आपो वा इदꣳसर्वं विश्वाभूतान्यापः प्राणा वा आपः पशव आपोऽन्नमापोऽमृतमाप-स्सम्राडापो विराडापस्स्वराडाप-श्छन्दाꣳ स्यापो ज्योतीꣳष्यापो यजूꣳष्यापस्सत्यमापस्सर्वा देवता आपो भूर्भुवस्सुवराप ओम्॥

In Public domain. Digitization Muthulakshmi Research Academy

अपः प्रणयति। श्रद्धा वा आपः। श्रद्धामेवारभ्य प्रणीय प्रचरति। अपः प्रणयति। यज्ञो वा आपः। यज्ञमेवारभ्य प्रणीय प्रचरति। अपः प्रणयति। वज्रो वा आपः। वज्रमेव भ्रातृव्येभ्यः प्रहृत्य प्रणीय प्रचरति। अपः प्रणयति। आपो वै रक्षोघ्नीः। रक्षसामपहत्यै। अपः प्रणयति। आपो वै देवानां प्रियंधाम। देवानामेव प्रियंधाम प्रणीय प्रचरति। अपः प्रणयति। आपो वै सर्वा देवताः। देवता एवारभ्य प्रणीय प्रचरति॥ अपः प्रणयति। आपो वै शान्ताः। शान्ताभिरेवास्य शुचꣳ शमयति॥ देवो वः सवितोत्पुनात्वच्छिद्रेण पवित्रेण वसोस्सूर्यस्य रश्मिभिः ॥३॥

स हि रत्नानि दाशुषे सुवाति सविता भगः। तं भागं चित्रमीमहे॥ कूर्चाग्रैः राक्षसान् घोरान् छिन्धि कर्मविघातिनः। त्वामर्पयामि कुम्भेऽस्मिन् साफल्यं कुरु कर्मणि॥ वृक्षराज-समुद्भूताः शाखायाः पल्लवत्वचः। युष्मान् कुम्भेष्वर्पयामि सर्वपापापनुत्तये। नालिकेर समुद्भूत त्रिणेत्र हरसंमित। शिखया दुरितं सर्वं पापं पीडां च मे नुद॥४॥

(कुम्भेषु वरुणावाहनम्) सर्वे समुद्राः सरितः तीर्थानि च नदाः ह्रदाः। आयान्तु देव पूजार्थं दुरित क्षय कारकाः॥ इमं मे वरुण श्रुधी हवमद्याच मृडय। त्वामवस्यु राचके॥ तत्त्वा यामि ब्रह्मणा वन्दमानस्तदाशास्ते यजमानो हविर्भिः। अहेडमानो वरुणेह बोध्युरुशꣳस मा न आयुः प्रमोषीः॥ ओं भूर्भुवस्सुवरोम्। एषु कुम्भेषु वरुणं ध्यायामि। वरुणमावाहयामि वरुणस्य इदमासनम्। वरुणाय नमः। सकलाराधनैः स्वर्चितम्॥५॥

In Public domain. Digitization Muthulakshmi Research Academy

॥ महान्यास मन्त्रपाठ प्रारम्भः ॥

॥ पंचाऽङ्ग रुद्रन्यासः ॥

अथातः पंचांगरुद्राणां न्यासपूर्वकं जपहोमार्चनाभिषेकविधिं व्याख्यास्यामः ॥

नमस्ते रुद्रमन्यव उतो त इषवे नमः। नमस्ते अस्तु धन्वने बाहुभ्यामुत ते नमः। या त इषुः शिवतमा शिवं बभूव ते धनुः। शिवा शरव्या या तव तया नो रुद्र मृडय ॥

कं खं गं घं ङं। यरलवशषसहों। ओं नमो भगवते रुद्राय। पूर्वांग रुद्राय नमः ॥१॥

अपैतु मृत्युरमृतन्न आगन्वैवस्वतो नो अभयं कृणोतु। पर्णं वनस्पतेरिवाभिनश्शीयता ँ रयिस्स चतान्नः शचीपतिः।

चं छं जं झं ञं। यरलवशषसहों। ओं नमो भगवते रुद्राय। दक्षिणांग रुद्राय नमः ॥२॥

निधनपतये नमः। निधनपतान्तिकाय नमः। ऊर्ध्वाय नमः। ऊर्ध्वलिंगाय नमः। हिरण्याय नमः। हिरण्यलिंगाय नमः। सुवर्णाय नमः। सुवर्णलिंगाय नमः। दिव्याय नमः। दिव्यलिंगाय नमः। भवाय नमः। भवलिंगाय नमः। शर्वाय नमः। शर्वलिंगाय नमः। शिवाय नमः। शिवलिंगाय नमः। ज्वलाय नमः। ज्वललिंगाय नमः। आत्माय नमः। आत्मलिंगाय नमः। परमाय नमः। परमलिंगाय नमः। एतत्सोमस्य सूर्यस्य सर्वलिंग ँ स्थापयति पाणिमन्त्रं पवित्रम् ॥

In Public domain. Digitization Muthulakshmi Research Academy

टं ठं डं ढं णं। यरलवशषसहों। ओं नमो भगवते रुद्राय। पश्चिमांग रुद्राय नमः ॥३॥

यो रुद्रो अग्नौ यो अप्सु य ओषधीषु यो रुद्रो विश्वाभुवनाविवेश तस्मै रुद्राय नमो अस्तु॥

तं थं दं धं नं। यरलवशषसहों। ओं नमो भगवते रुद्राय। उत्तरांग रुद्राय नमः ॥४॥

प्राणानां ग्रन्थिरसि रुद्रो मा विशान्तकः। तेनान्नेनाप्यायस्व। नमो रुद्राय विष्णवे मृत्युर्मे पाहि॥

पं फं बं भं मं। यरलवशषसहों। ओं नमो भगवते रुद्राय। ऊर्ध्वांग रुद्राय नमः ॥५॥

॥ पञ्चमुख न्यासः ॥

१) तत्पुरुषाय विद्महे महादेवाय धीमहि। तन्नो रुद्रः प्रचोदयात्॥

संवर्ताग्नि तटित्प्रदीप्त कनकप्रस्पर्धि तेजोरुणं
गम्भीरध्वनि सामवेदजनकं ताम्राधरं सुन्दरम्।
अर्धेन्दुद्युति लोल पिंगल जटा भार प्रबोद्धोदकं
वन्दे सिद्धसुरासुरेन्द्र नमितं पूर्वं मुखं शूलिनः॥
ओं नमो भगवते रुद्राय। पूर्वाङ्गमुखाय नमः॥

२) अघोरेभ्योऽथ घोरेभ्यो घोरघोरतरेभ्यः। सर्वेभ्यः सर्वशर्वेभ्यो नमस्ते अस्तु रुद्ररूपेभ्यः॥

कालाभ्र भ्रमराञ्जन द्युतिनिभं व्यावृत्तपिंगेक्षणं
कर्णोद्भासित भोगिमस्तकमणि प्रोद्भिन्नदंष्ट्रांकुरम्।

In Public domain. Digitization Muthulakshmi Research Academy

सर्पप्रोतकपाल शुक्तिशकल व्याकीर्णताशेखरं
वन्दे दक्षिणमीश्वरस्य वदनं चाथर्वनादोदयम्॥
ओं नमो भगवते रुद्राय। दक्षिणांग मुखाय नमः॥

३) सद्योजातं प्रपद्यामि सद्यो जाताय वै नमो नमः।
भवे भवे नातिभवे भवस्व माम्। भवोद्भवाय नमः॥

प्रालेयाचलमिन्दुकुन्दधवलं गोक्षीरफेनप्रभं
भस्माभ्यंग मनंग देहदहन ज्वालावलीलोचनम्।
विष्णुब्रह्म मरुद्गणार्चित पदं चर्ग्वेदनादोदयं
वन्देऽहं सकलं कलंकरहितं स्थाणोर्मुखं पश्चिमम्॥
ओं नमो भगवते रुद्राय। पश्चिमांग मुखाय नमः॥

४) वामदेवाय नमो ज्येष्ठाय नमः श्रेष्ठाय नमो रुद्राय नमः कालाय नमः कलविकरणाय नमो बलविकरणाय नमो बलाय नमो बलप्रमथनाय नमस्सर्व भूतदमनाय नमो मनोन्मनाय नमः॥

गौरं कुंकुम पंकिळं सुतिलकं व्यापाण्डु गण्डस्थलं
भ्रूविक्षेप कटाक्षवीक्षणलसत् संसक्तकर्णोत्पलम्।
स्निग्धं बिम्बफलाधरं प्रहसितं नीलालकालंकृतं
वन्दे याजुष वेदघोषजनकं वक्त्रं हरस्योत्तरम्॥
ओं नमो भगवते रुद्राय। उत्तरांग मुखाय नमः॥

५) ईशानस्सर्वविद्यानामीश्वरः सर्व भूतानां ब्रह्माधिपति-
र्ब्रह्मणोधिपतिर्ब्रह्मा शिवो मे अस्तु सदाशिवोम्॥

व्यक्ताव्यक्त निरूपितं च परमं षट्त्रिंश तत्त्वाधिकं
तस्मादुत्तरतत्त्व मक्षरमिति ध्येयं सदा योगिभिः।

In Public domain. Digitization Muthulakshmi Research Academy

ओंकारादिसमस्त मन्त्रजनकं सूक्ष्मातिसूक्ष्मं परं
वन्दे पंचममीश्वरस्य वदनं ख-व्यापि तेजोमयम्॥
ओं नमो भगवते रुद्राय। ऊर्ध्वांग मुखाय नमः॥

॥ केशादि पादान्त न्यासः ॥

या ते रुद्र शिवातनूरघोरापाप काशिनी। तया न स्तनुवा शन्तमया गिरिशन्ताभिचाकशीहि॥ शिखायै नमः॥

अस्मिन्महत्यर्णवे ऽन्तरिक्षे भवा अधि। तेषाꣳसहस्र-योजनेऽवधन्वानि तन्मसि॥ शिरसे नमः॥

सहस्राणि सहस्रशो ये रुद्रा अधि भूम्याम्। तेषाꣳ सहस्रयोजने ऽवधन्वानि तन्मसि॥ ललाटाय नमः॥

हꣳसश्शुचिषद्वसुरन्तरिक्षसद्धोता वेदिषदतिथि र्दुरोणसत्। नृषद्वरसदृत सद्व्योमसदब्जा गोजा ऋतजा अद्रिजा ऋतं बृहत्॥ भ्रुवोर्मध्याय नमः॥

त्र्यम्बकं यजामहे सुगन्धिं पुष्टिवर्धनम्। उर्वारुकमिव बन्धनान्मृत्योर्मुक्षीय माऽमृतात्॥ नेत्राभ्यां नमः॥

नमः स्रुत्याय च पथ्याय च नमः काट्याय च नीप्याय च नमः सूद्याय च सरस्याय च नमो नाद्याय च वैशन्ताय च॥ कर्णाभ्यां नमः॥

मा नस्तोके तनये मा न आयुषि मा नो गोषु मा नो अश्वेषु रीरिषः। वीरान्मानो रुद्र भामितो वधीरहविष्मन्तो नमसा विधेम ते॥ नासिकाभ्यां नमः॥

अवतत्य धनुस्त्वꣳ सहस्राक्ष शतेषुधे। निशीर्य शल्यानां मुखा शिवो नः सुमना भव॥ मुखाय नमः॥

In Public domain. Digitization Muthulakshmi Research Academy

नीलग्रीवाश्शितिकण्ठाश्शर्वा अधः क्षमाचराः। तेषाँ सहस्त्रयोजनेऽवधन्वानि तन्मसि॥ कण्ठाय नमः॥

नीलग्रीवाश्शितिकण्ठा दिवँ रुद्रा उपश्रिताः। तेषाँ सहस्त्रयोजनेऽवधन्वानि तन्मसि॥ उपकण्ठाय नमः॥

नमस्ते अस्त्वायुधायानातताय धृष्णवे। उभाभ्यामुत ते नमो बाहुभ्यां तव धन्वने॥ बाहुभ्यां नमः॥

या ते हेतिर्मीढुष्टम हस्ते बभूव ते धनुः। तयाऽस्मान् विश्वतस्त्व मयक्ष्मया परिब्भुज॥ उपबाहुभ्यां नमः॥

परिणो रुद्रस्य हेतिर्वृणक्तु परित्वेषस्य दुर्मतिरघायोः। अवस्थिरा मघवद्भ्यस्तनुष्व मीढ्वस्तोकाय तनयाय मृडय॥ मणिबन्धाभ्यां नमः॥

ये तीर्थानि प्रचरन्ति सृकावन्तो निषंगिणः। तेषाँ सहस्त्रयोजनेऽव धन्वानि तन्मसि॥ हस्ताभ्यां नमः॥

सद्यो जातं प्रपद्यामि सद्यो जाताय वै नमो नमः। भवे भवे नातिभवे भवस्व माम्। भवोद्भवाय नमः॥ अंगुष्ठाभ्यां नमः॥

वामदेवाय नमो ज्येष्ठाय नमः श्रेष्ठाय नमो रुद्राय नमः कालाय नमः कलविकरणाय नमो बलविकरणाय नमो बलाय नमो बलप्रमथनाय नमः सर्वभूतदमनाय नमो मनोन्मनाय नमः॥ तर्जनीभ्यां नमः॥

अघोरेभ्योऽथघोरेभ्यो घोरघोरतरेभ्यः। सर्वेभ्यः सर्वशर्वेभ्यो नमस्ते अस्तु रुद्ररूपेभ्यः॥ मध्यमाभ्यां नमः॥

तत्पुरुषाय विद्महे महादेवाय धीमहि। तन्नो रुद्रः प्रचोदयात्॥ अनामिकाभ्यां नमः॥

In Public domain. Digitization Muthulakshmi Research Academy

ईशानः सर्वविद्याना मीश्वरः सर्वभूतानां ब्रह्माधिपति-ब्रह्मणोऽधिपतिर्ब्रह्मा शिवो मे अस्तु सदाशिवोम्॥ कनिष्ठिकाभ्यां नमः॥

नमो हिरण्यबाहवे हिरण्यवर्णाय हिरण्यरूपाय हिरण्य-पतयेऽम्बिकापतय उमापतये पशुपतये नमो नमः। करतलकर-पृष्ठाभ्यां नमः।

नमो वः किरिकेभ्यो देवानाꣳ हृदयेभ्यः॥ हृदयाय नमः॥

नमो गणेभ्यो गणपतिभ्यश्च वो नमः। पृष्ठाय नमः॥

नमस्तक्षभ्यो रथकारेभ्यश्च वो नमः। कक्षाभ्यां नमः॥

नमो हिरण्यबाहवे सेनान्ये दिशां च पतये नमः॥ पार्श्वाभ्यां नमः॥

विज्यं धनुः कपर्दिनो विशल्यो बाणवाꣳउत। अनेशन्नस्येषव आभुरस्य निषंगथिः। जठराय नमः॥

हिरण्यगर्भस्समवर्तताग्रे भूतस्य जातः पतिरेक आसीत्। सदाधार पृथिवीन्द्यामुतेमां कस्मै देवाय हविषा विधेम॥ नाभ्यै नमः॥

मीढुष्टम शिवतम शिवोनस्सुमना भव। परमे वृक्ष आयुधं निधाय कृत्तिं वसान आचर पिनाकं बिभ्रदागहि॥ कट्यै नमः॥

ये भूतानामधिपतयो विशिखासः कपर्दिनः। तेषाꣳ सहस्त्रयोजनेऽव धन्वानि तन्मसि। गुह्याय नमः॥

ये अन्नेषु विविध्यन्ति पात्रेषु पिबतो जनान्। तेषाꣳ सहस्त्रयोजनेऽव धन्वानि तन्मसि। अण्डाभ्यां नमः॥

In Public domain. Digitization Muthulakshmi Research Academy

स शिरा जातवेदा अक्षरं परमं पदम्। वेदानाꣳशिरसि माताऽऽयुष्मन्तं करोतु माम्॥ अपानाय नमः॥

मानो महान्तमुत मानो अर्भकं मा न उक्षन्तमुत मा न उक्षितम्। मा नो वधीः पितरं मोत मातरं प्रिया मा नस्तनुवो रुद्र रीरिषः॥ ऊरुभ्यां नमः॥

एष ते रुद्रभागस्तञ्जुषस्व तेनावसेन परो मूजवतोऽतीह्यवततधन्वा पिनाकहस्तः कृत्तिवासाः॥ जानुभ्यां नम॥

सꣳसृष्टजित्सोमपा बाहुशर्ध्यूर्ध्वधन्वा प्रतिहिताभिरस्ता। बृहस्पते परिदीया रथेन रक्षोहाऽमित्राꣳ अपबाधमानः॥ जंघाभ्यां नमः॥

विश्वं भूतं भुवनं चित्रं बहुधा जातं जायमानं च यत्। सर्वो ह्येष रुद्रस्तस्मै रुद्राय नमो अस्तु॥ गुल्फाभ्यां नमः॥

ये पथां पथिरक्षय ऐलबृदा यव्युधः। तेषाꣳ सहस्त्र योजनेऽवधन्वानि तन्मसि॥ पादाभ्यां नमः॥

अध्यवोचदधिवक्ता प्रथमो दैव्यो भिषक्। अहीꣳश्च सर्वाञ्जम्भयन् सर्वांश्च यातुधान्यः॥ कवचाय हुम्॥

नमो बिल्मिने च कवचिने च नमः श्रुताय च श्रुतसेनाय च॥ उपकवचाय हुम्॥

नमो अस्तु नीलग्रीवाय सहस्त्राक्षाय मीढुषे। अथो ये अस्य सत्वानोऽहन्तेभ्यो करन्नमः॥ नेत्रत्रयाय वौषट्॥ (तृतीयनेत्राय वौष्ट् इति पाठभेदः)।

प्रमुंच धन्वनस्त्वमुभयोरार्त्नियोर्ज्याम्। या श्च ते हस्त इषवः परा ता भगवो वप॥ अस्त्राय फट्॥

In Public domain. Digitization Muthulakshmi Research Academy

य एतावन्तश्च भूयाꣳसश्च दिशो रुद्रा वितस्थिरे। तेषाꣳसहस्रयोजनेऽवधन्वानि तन्मसि॥ इति दिग्बन्धः।

॥ दशाङ्ग न्यासः ॥

ओं—मूर्ध्ने नमः। नं—नासिकाभ्यां नमः। मों—ललाटाय नमः। भं—मुखाय नमः। गं—कण्ठाय नमः। वं—हृदयाय नमः। तें—दक्षिण हस्ताय नमः। रुं—वामहस्ताय नमः। द्रां—नाभ्यै नमः। यं—पादाभ्यां नमः॥

॥ पञ्चाङ्ग न्यासः ॥

सद्योजातं प्रपद्यामि सद्यो जाताय वै नमो नमः। भवे भवे नातिभवे भवस्व मां। भवोद्भवाय नमः॥ पादाभ्यां नमः॥

वामदेवाय नमो ज्येष्ठाय नमः श्रेष्ठाय नमो रुद्राय नमः कालाय नमः कलविकरणाय नमो बलविकरणाय नमो बलाय नमो बलप्रमथनाय नम स्सर्व भूतदमनाय नमो मनोन्मनाय नमः॥ ऊरु(मध्यमा)भ्यां नमः॥

अघोरेऽभ्योऽथ घोरेभ्यो घोरघोरतरेभ्यः। सर्वेभ्य-स्सर्वशर्वेभ्यो नमस्ते अस्तु रुद्ररूपेभ्यः॥ हृदयाय नमः॥

तत्पुरुषाय विद्महे महादेवाय धीमहि। तन्नो रुद्रः प्रचोदयात्॥ मुखाय नमः॥

ईशानस्सर्वविद्याना मीश्वरस्सर्व भूतानां ब्रह्माधिपति-र्ब्रह्मणोधिपति र्ब्रह्मा शिवो मे अस्तु सदाशिवोम्॥ मूर्ध्ने नमः॥

★★★

In Public domain. Digitization Muthulakshmi Research Academy

॥ हंसगायत्री ॥

अस्य श्री हंसगायत्री स्तोत्र महामन्त्रस्य, अव्यक्त परब्रह्म ऋषिः, अव्यक्त गायत्री छन्दः, परमहंसो देवता॥ हंसां—बीजम्, हंसीं—शक्तिः, हंसूं—कीलकम्॥ परमहंस प्रसाद सिद्ध्यर्थे जपे विनियोगः॥

हंसां—अंगुष्ठाभ्यां नमः। हंसीं—तर्जनीभ्यां नमः। हंसूं—मध्यमाभ्यां नमः। हंसैं—अनामिकाभ्यां नमः। हंसौं—कनिष्ठिकाभ्यां नमः। हंसः—करतल करपृष्ठाभ्यां नमः॥

हंसां—हृदयाय नमः। हंसीं—शिरसे स्वाहा। हंसूं—शिखायै वषट्। हंसैं—कवचाय हुं। हंसौं-नेत्रत्रयाय वौषट्। हंसः अस्त्राय फट्॥ भूर्भुवस्सुवरोमिति दिग्बन्धः॥

॥ ध्यानम्॥

गमागमस्थं गमनादिशून्यं चिद्रूपदीपं तिमिरापहारम्। पश्यामि ते सर्वजनान्तरस्थं नमामि हंसं परमात्मरूपम्॥ (देहो देवालयः प्रोक्तो जीवो देवस्सनातनः। त्यजेदज्ञान निर्माल्यं सोऽहं भावेन पूजयेत्।) हंसो हंसः परम हंसः। हंसस्सोहं सोहं हंसः॥ हुंस हुंसार्य विद्महे परमहुंसार्य धीमहि। तन्नौ हंसः प्रचोदयात्॥

हंस हंसेति यो ब्रूयाद्धंसो नाम सदाशिवः। एवं न्यास विधिं कृत्वा ततः संपुटमारभेत्॥

॥ दिक्सम्पुटन्यासः ॥

ओं भूर्भुवस्सुवरोम्। ओं लं—त्रातारमिन्द्र मवितारमिन्द्रꣳ हवैं हवे सुहवꣳ शूरमिन्द्रम्। हुवे नु शक्रं पुरुहूतमिन्द्रꣳ स्वस्ति नो मघवा धात्विन्द्रः॥ ओं लं—भूर्भुवस्सुवः-इन्द्राय वज्रहस्ताय

In Public domain. Digitization Muthulakshmi Research Academy

सुराधिपतये ऐरावतवाहनाय सांगाय सायुधाय सशक्तये-सपरिवाराय सर्वालंकारभूषिताय उमामहेश्वर पार्षदाय नमः। पूर्व दिग्भागे इन्द्राय नमः। ललाटस्थाने इन्द्राय नमः। इन्द्रः सुप्रीतो वरदो भवतु॥

ओं भूर्भुवस्सुवरोम्। नं रं—त्वन्नो अग्ने वरुणस्य विद्वान् देवस्य हेडोऽवं यासिसीष्ठाः। यजिष्ठो वह्नितमश्शोशुचानो विश्वा द्वेषाꣳसि प्रमुमुग्ध्यस्मत्॥ नं रं—भूर्भुवस्सुवः! अग्नये शक्ति-हस्ताय तेजोऽधिपतये अजवाहनाय सांगाय सायुधाय सशक्तये सपरिवाराय सर्वालंकार भूषिताय उमामहेश्वर पार्षदाय नमः। आग्नेयदिग्भागे अग्नये नमः। नेत्रयोःस्थाने अग्नये नमः। अग्निः सुप्रीतो वरदो भवतु॥

ओं भूर्भुवस्सुवरोम्। मों हं—सुगन्नः पन्थामभयं कृणोतु। यस्मिन्नक्षत्रे यम एति राजा। यस्मिन्नेन मभ्यषिंचन्त देवाः। तदस्य चित्रꣳहविषा यजाम॥ मों हं—भूर्भुवस्सुवः-यमाय दण्डहस्ताय धर्माधिपतये महिषवाहनाय सांगाय सायुधाय सशक्तये सपरिवाराय सर्वालंकार भूषिताय उमामहेश्वर पार्षदाय नमः। दक्षिण दिग्भागे यमाय नमः। कर्णयोस्स्थाने यमाय नमः। यमः सुप्रीतो वरदो भवतु॥

ओं भूर्भुवस्सुवरोम्। भं षं—असुन्वन्तमयजमान मिच्छ स्तेनस्येत्या न्तस्करस्यान्वैषि। अन्यमस्मदिच्छ सा त इत्या नमो देवि निरृते तुभ्यमस्तु॥ भं षं—भूर्भुवस्सुवः। निरृतये खड्ग हस्ताय रक्षोधिपतये नरवाहनाय सांगाय सायुधाय सशक्तये सपरिवाराय सर्वालंकार भूषिताय उमामहेश्वर पार्षदाय नमः।

In Public domain. Digitization Muthulakshmi Research Academy

निर्ऋतिदिग्भागे निर्ऋतये नमः। मुखस्थाने निर्ऋतये नमः। निर्ऋतिस्सुप्रीतो वरदो भवतु॥

ओं भूर्भुवस्सुवरोम्। गं वं—तत्त्वा यामि ब्रह्मणा वन्दमानस्तदा शास्ते यजमानो हविर्भिः। अहेडमानो वरुणेहबोध्युरुश ँ स मा न आयुः प्रमोषीः॥ गं वं—भूर्भुवस्सुवः-वरुणाय पाश हस्ताय जलाधिपतये मकरवाहनाय सांगाय सायुधाय सशक्तये सपरिवाराय सर्वालंकार भूषिताय उमामहेश्वर पार्षदाय नमः। पश्चिमदिग्भागे वरुणाय नमः। बाहुवोस्स्थाने वरुणाय नमः। वरुणः सुप्रीतो वरदो भवतु॥

ओं भूर्भुवस्सुवरोम्। वं यं—आ नो नियुद्भिश्शतिनीभिरध्वरम्। सहस्त्रिणीभिरुपयाहि यज्ञम्। वायो अस्मिन् हविषि मादयस्व। यूयं पात स्वस्तिभिस्सदा नः॥ वं यं—भूर्भुवस्सुवः-वायवे सांकुशध्वजहस्ताय प्राणाधिपतये मृग-वाहनाय सांगाय सायुधाय सशक्तये सपरिवाराय सर्वालंकार भूषिताय उमामहेश्वर पार्षदाय नमः। वायव्य दिग्भागे वायवे नमः। नासिकयोः स्थाने वायवे नमः। वायुः सुप्रीतो वरदो भवतु॥

ओं भूर्भुवस्सुवरोम्। तें सं—वय ँ सोम व्रते तव। मनस्तनूषु बिभ्रतः। प्रजावन्तो अशीमहि॥ तें सं—भूर्भुवस्सुवः-सोमाय अमृतकलशहस्ताय नक्षत्राधिपतये अश्ववाहनाय सांगाय सायुधाय सशक्तये सपरिवाराय सर्वालंकार भूषिताय उमामहेश्वर पार्षदाय नमः। उत्तरदिग्भागे सोमाय नमः। हृदयस्थाने सोमाय नमः। सोमः सुप्रीतो वरदो भवतु॥

In Public domain. Digitization Muthulakshmi Research Academy

ओं भूर्भुवस्सुवरोम्। रुं शं—तमीशानं जगतस्तस्थुषस्पतिम्। धियं जिन्वमवसे हूमहे वयम्। पूषा नो यथा वेदसामसद् वृधे। रक्षिता पायुरदब्धस्स्वस्तये॥ रुं शं—भूर्भुवस्सुवः। ईशानाय त्रिशूलहस्ताय भूताधिपतये वृषभवाहनाय सांगाय सायुधाय सशक्तये सपरिवाराय सर्वालंकार भूषिताय उमामहेश्वर पार्षदाय नमः। ईशानदिग्भागे ईशानाय नमः। नाभिस्थाने ईशानाय नमः। ईशानः सुप्रीतो वरदो भवतु॥

ओं भुर्भुवस्सुवरोम्। द्रां खं—अस्मे रुद्रा मेहना पर्वतासो वृत्रहत्ये भरहूतौ सजोषाः। यश्शंसते स्तुवते धायि वज्र इन्द्रज्येष्ठा अस्मां अवन्तु देवाः॥ द्रां खं—भूर्भुवस्सुवः। ब्रह्मणे पद्महस्ताय प्रजाधिपतये हंसवाहनाय सांगाय सायुधाय सशक्तये सपरिवाराय सर्वालंकार भूषिताय उमामहेश्वर पार्षदाय नमः। ऊर्ध्वदिग्भागे ब्रह्मणे नमः। मूर्ध्निस्थाने ब्रह्मणे नमः। ब्रह्मा सुप्रीतो वरदो भवतु॥

ओं भूर्भुवस्सुवरोम्। यं ह्रीं—स्योना पृथिवि भवानृक्षरा निवेशनी। यच्छानश्शर्म सप्रथाः। यं ह्रीं—भूर्भुवस्सुवः। विष्णवे चक्रहस्ताय नागाधिपतये गरुडवाहनाय सांगाय सायुधाय सशक्तये सपरिवाराय सर्वालंकार भूषिताय उमामहेश्वर पार्षदाय नमः। अधोदिग्भागे विष्णवे नमः। पादयोस्स्थाने विष्णवे नमः। विष्णुस्सुप्रीतो वरदो भवतु॥

॥ षोडशाङ्ग रौद्रीकरणम् ॥

ओं भूर्भुवस्सुवः। ओं अं। नमश्शंभवे च मयोभवे च नमश्शंकराय च मयस्कराय च नमश्शिवाय च शिवतराय च॥

In Public domain. Digitization Muthulakshmi Research Academy

विभूरसि प्रवाहणो रौद्रेणानीकेन पाहि माऽग्ने पिपृहि मा मा मा हिंसीः ॥ अं भूर्भुवस्सुवरोम्। शिखास्थाने रुद्राय नमः ॥

ओं भूर्भुवस्सुवः। ओं आं। नमश्शंभवेच मयोभवे च नमश्शंकराय च मयस्कराय च नमश्शिवाय च शिवतराय च। वह्निरसि हव्यवाहनो रौद्रेणानीकेन पाहिमाऽग्ने पिपृहि मा मा मा हिंसीः ॥ आं भूर्भुवस्सुवरोम्। शिरःस्थाने रुद्राय नमः ॥

ओं भूर्भुवस्सुवः। ओं इं। नमः शंभवे च मयोभवे च नमश्शंकराय च मयस्कराय च नमश्शिवाय च शिवतराय च। श्वात्रोसि प्रचेता रौद्रेणानीकेन पाहिमाऽग्ने पिपृहि मा मा मा हिंसीः। इं भूर्भुवस्सुवरोम्॥ मूर्ध्नि(मूर्ध)स्थाने रुद्राय नमः ॥

ओं भूर्भुवस्सुवः। ओं ईं। नमः शंभवे च मयोभवे च नमश्शंकराय च मयस्कराय च नमश्शिवाय य शिवतराय च। तुथोसि विश्ववेदा रौद्रेणानीकेन पाहिमाऽग्ने पिपृहि मा मा मा हिंसीः। ईं भूर्भुवस्सुवरोम्॥ ललाटस्थाने रुद्राय नमः ॥

ओं भूर्भुवस्सुवः। ओं उं। नमः शंभवे च मयोभवे च नमश्शंकराय च मयस्कराय च नमश्शिवाय च शिवतराय च। उशिगसिकवी रौद्रेणानीकेन पाहिमाऽग्ने पिपृहि मा मा मा हिंसीः। उं भूर्भुवस्सुवरोम्॥ भ्रुवोः(भ्रू)स्थाने रुद्राय नमः ॥

ओं भूर्भुवस्सुवः। ओं ऊं। नमः शंभवे च मयोभवे च नमश्शंकराय च मयस्कराय च नमश्शिवाय च शिवतराय च। अंघारिरसि बंभारी रौद्रेणानीकेन पाहिमाऽग्ने पिपृहि मा मा मा हिंसीः। ऊं भूर्भुवस्सुवरोम्। मुखस्थाने रुद्राय नमः ॥

In Public domain. Digitization Muthulakshmi Research Academy

ओं भूर्भुवस्सुवः। ओं ॠं। नमः शंभवे च मयोभवे च नमश्शंकराय च मयस्कराय च नमश्शिवाय च शिवतराय च। अवस्युरसि दुवस्वान् रौद्रेणानीकेन पाहिमाऽग्ने पिपृहि मा मा मा हिंसीः। ॠं भूर्भुवस्सुवरोम्॥ कण्ठस्थाने रुद्राय नमः॥

ओं भूर्भुवस्सुवः। ओं ॠं। नमः शंभवे च मयोभवे च नमश्शंकराय च मयस्कराय च नमश्शिवाय य शिवतराय च। शुन्ध्यूरसि मार्जालीयो रौद्रेणानीकेन पाहिमाऽग्ने पिपृहि मा मा मा हिंसीः। ॠं भूर्भुवस्सुवरोम्॥ बाह्वोःस्थाने रुद्राय नमः॥

ओं भूर्भुवस्सुवः। ओं लृं। नमः शंभवे च मयोभवे च नमश्शंकराय च मयस्कराय च नमश्शिवाय च शिवतराय च। सम्राडसि कृशानू रौद्रेणानीकेन पाहिमाऽग्ने पिपृहि मा मा मा हिंसीः। लृं भूर्भुवस्सुवरोम्॥ उरस्थाने रुद्राय नमः॥

ओं भूर्भुवस्सुवः। ओं लृं। नमः शंभवे च मयोभवे च नमश्शंकराय च मयस्कराय च नमश्शिवाय च शिवतराय च। परिषद्योसि पवमानो रौद्रेणानीकेन पाहिमाऽग्ने पिपृहि मा मा मा हिंसीः। लृं भूर्भुवस्सुवरोम्॥ हृदयस्थाने रुद्राय नमः॥

ओं भूर्भुवस्सुवः। ओं एं। नमः शंभवे च मयोभवे च नमश्शंकराय च मयस्कराय च नमश्शिवाय च शिवतराय च। प्रतक्वासि नभस्वान् रौद्रेणानीकेन पाहिमाऽग्ने पिपृहि मा मा मा हिंसीः। एं भूर्भुवस्सुवरोम्॥ नाभिस्थाने रुद्राय नमः॥

ओं भूर्भुवस्सुवः। ओं ऐं। नमः शंभवे च मयोभवे च नमश्शंकराय च मयस्कराय च नमश्शिवाय च शिवतराय च।

In Public domain. Digitization Muthulakshmi Research Academy

असंमृष्टोसि हव्यसूदो रौद्रेणानीकेन पाहिमाँऽग्ने पिपृहि मा मा मा हिंसीः। ऐं भूर्भुवस्सुवरोम्। कटिस्थाने रुद्राय नमः॥

ओं भूर्भुवस्सुवः। ओं ओं। नमः शंभवे च मयोभवे च नमश्शंकराय च मयस्कराय च नमश्शिवाय च शिवतराय च। ऋतधामासि सुवर्ज्योती रौद्रेणानीकेन पाहिमाँऽग्ने पिपृहि मा मा मा हिंसीः। ओं भूर्भुवस्सुवरोम्। ऊरुस्थाने रुद्राय नमः॥

ओं भूर्भुवस्सुवः। ओं औं। नमः शंभवे च मयोभवे च नमश्शंकराय च मयस्कराय च नमश्शिवाय च शिवतराय च। ब्रह्मज्योतिरसि सुवर्धामा रौद्रेणानीकेन पाहिमाँऽग्ने पिपृहि मा मा मा हिंसीः। औं भूर्भुवस्सुवरोम्। जान्वोःस्थाने रुद्राय नमः॥

ओं भुर्भुवस्सुवः। ओं अं। नमः शंभवे च मयोभवे च नमश्शंकराय च मयस्कराय च नमश्शिवाय च शिवतराय च। अजोँस्येकपाद् रौद्रेणानीकेन पाहिमाँऽग्ने पिपृहि मा मा मा हिंसीः। अं भूर्भुवस्सुवरोम्॥ जंघयोः(जंघा)स्थाने रुद्राय नमः॥

ओं भूर्भुवस्सुवः। ओं अः। नमः शंभवे च मयोभवे च नमश्शंकराय च मयस्कराय च नमश्शिवाय च शिवतराय च। अहिरसि बुध्नियो रौद्रेणानीकेन पाहि माँग्ने पिपृहि मा मा मा हिंसीः॥ अः। भूर्भुवस्सुवरोम्॥ पादयोःस्थाने रुद्राय नमः॥

त्वगस्थिगतैः सर्वपापैः प्रमुच्यते। सर्वभूतेष्वपराजितो भवति। ततो भूतप्रेत-पिशाच-ब्रह्मराक्षस-यक्ष-यमदूत- शाकिनी-डाकिनी-सर्प-श्वापद-वृश्चिक-तस्करा- द्युपद्रवा-द्युपघाताः। सर्वे ज्वलन्तं पश्यन्तु। मां रक्षन्तु॥ सर्वान् महाजनान् रक्षन्तु।

In Public domain. Digitization Muthulakshmi Research Academy

॥ गुह्यादि मस्तकान्तं षडङ्ग न्यासः ॥

मनो ज्योतिर्जुषता माज्यं विच्छिन्नं यज्ञꣳ समिमं दधातु। या इष्टा उषसो निम्रुचश्च तास्सन्दधामि हविषा घृतेन॥ गुह्याय नमः॥

अबो"द्ध्यग्निस्समिधा जनानां प्रति धेनुमिवायती मुषासम्। यह्वा इव प्रवयामुज्जिहानाः प्रभानवस्सिस्रते नाकमच्छ॥ नाभ्यै नमः॥

अग्निर्मूर्धा दिवः ककुत् पतिः पृथिव्या अयम्। अपाꣳरेताꣳसि जिन्वति॥ हृदयाय नमः॥

मूर्धानं दिवो अरतिं पृथिव्या वै"श्वानरमृताय जातमग्निम्। कविꣳसम्राज मतिथिं जनानामासन्ना पात्रं जनयन्त देवाः॥ कण्ठाय नमः॥

मर्माणि ते वर्मभिश्छादयामि सोमस्त्वा राजाऽमृतेनाभि वस्ताम्। उरोर्वरीयो वरिवस्ते अस्तु जयन्तं त्वा मनुमदन्तु देवाः॥ मुखाय नमः॥

जातवेदा यदि वा पावकोऽसि। वैश्वानरो यदि वा वैद्युतोऽसि। शंप्रजाभ्यो यजमानाय लोकम्॥ ऊर्जं पुष्टिं दर्दद्भ्यावव्वृत्स्व॥ शिरसे नमः॥

॥ आत्म रक्षा ॥

ब्रह्मात्मन्वदसृजत। तदकामयत। समात्मना पद्येयेति। आत्मन्नात्मन्नित्यामन्त्रयत। तस्मै दशमꣳ हूतः प्रत्यशृणोत्। स दशहूतोऽभवत्। दशहूतो हवै नामैषः। तं वा एतं दशहूतꣳसन्तम्। दशहोतेत्याचक्षते परोक्षेण। परोक्षप्रिया इव हि देवाः॥

In Public domain. Digitization Muthulakshmi Research Academy

आत्मन्नात्मन्नित्यामन्त्रयत। तस्मै सप्तमꣳ हूतः प्रत्यशृणोत्। स सप्तहूतोऽभवत्। सप्तहूतोहवै नामैषः। तं वा एतꣳ सप्तहूतꣳसन्तम्। सप्तहोतेत्याचक्षते परोक्षेण। परोक्षप्रिया इव हि देवाः॥

आत्मन्नात्मन्नित्यामन्त्रयत। तस्मै षष्ठꣳहूतः प्रत्यशृणोत्। स षड्ढूतोऽभवत्। षड्ढूतो हवै नामैषः। तं वा एतꣳ षड्ढूतꣳ सन्तम्। षड् ढोतेत्याचक्षते परोक्षेण। परोक्षप्रिया इव हि देवाः॥

आत्मन्नात्मन्नित्यामन्त्रयत। तस्मै पञ्चमꣳ हूतः प्रत्यशृणोत्। स पञ्चहूतोऽभवत्। पञ्चहूतो हवै नामैषः। तं वा एतं पञ्चहूतꣳ सन्तम्। पञ्चहोतेत्याचक्षते परोक्षेण। परोक्षप्रिया इव हि देवाः॥

आत्मन्नात्मन्नित्यामन्त्रयत। तस्मै चतुर्थꣳ हूतः प्रत्यशृणोत्। स चतुर्हूतोऽभवत्। चतुर्हूतो हवै नामैषः। तं वा एतं चतुर्हूतꣳसन्तम्। चतुर्होतेत्याचक्षते परोक्षेण। परोक्षप्रिया इव हि देवाः॥

तमब्रवीत्। त्वं वै मे नेदिष्ठꣳ हूतः प्रत्यश्रौषीः। त्वयै नानाख्यातार इति। तस्मान्नुहैनाꣳ श्चतुर्होतार इत्याचक्षते। तस्माच्छुश्रूषुः पुत्राणाꣳ हृद्यतमः। नेदिष्ठो हृद्यतमः। नेदिष्ठो ब्रह्मणो भवति। य एवं वेद॥ आत्मने नमः।

॥ शिवसंकल्पः ॥

येनेदं भूतं भुवनं भविष्यत् परिगृहीतममृतेन सर्वम्। येन यज्ञस्तायते सप्तहोता तन्मे मनःशिवसंकल्पमस्तु॥

येन कर्माणि प्रचरन्ति धीरा यतो वाचा मनसा चारु यन्ति। यत्सम्मित मनुसंयन्ति प्राणिनस्तन्मे मनःशिव-संकल्पमस्तु॥

In Public domain. Digitization Muthulakshmi Research Academy

येन कर्माण्यपसो मनीषिणो यज्ञे कृण्वन्ति विदथेषु धीराः। यदपूर्वं यक्षमन्तः प्रजानां तन्मे मनः शिवसंकल्पमस्तु॥

यत्प्रज्ञानमुत चेतो धृतिश्च यज्ज्योतिरन्तरमृतं प्रजासु। यस्मान्न ऋते किंचन कर्म क्रियते तन्मे मनः शिवसंकल्पमस्तु॥

सुषारथिरश्वानिव यन्मनुष्यान्नेनीयतेऽभीशुभिर्वाजिन इव। हृत्प्रतिष्ठं यदजिरं जविष्ठं तन्मे मनः शिवसंकल्पमस्तु॥

यस्मिन्नृचस्साम यजूꣳषि यस्मिन् प्रतिष्ठिता रथनाभाविवाराः। यस्मिꣳश्चित्तꣳ सर्वमोतं प्रजानां तन्मे मनः शिवसंकल्पमस्तु॥

यदत्र षष्ठं त्रिशतꣳसुवीरं यज्ञस्य गुह्यं नवनावमाय्यम्। दश पंच त्रिꣳशतं यत्परं च तन्मे मनः शिवसंकल्पमस्तु॥

यज्जाग्रतो दूरमुदैति दैवं तदु सुप्तस्य तथैवैति। दूरंगमं ज्योतिषां ज्योतिरेकं तन्मे मनः शिवसंकल्पमस्तु॥

येन द्यौः पृथिवी चान्तरिक्षं च ये पर्वताः प्रदिशो दिशश्च। येनेदं जगद्व्याप्तं प्रजानां तन्मे मनः शिवसंकल्पमस्तु॥

येनेदं विश्वं जगतो बभूव ये देवापि महतो जातवेदाः। तदेवाग्निस्तमसो ज्योतिरेकं तन्मे मनः शिवसंकल्पमस्तु॥

ये मनो हृदयं ये च देवा ये दिव्या आपो ये सूर्यरश्मिः। ते श्रोत्रे चक्षुषी सञ्चरन्तं तन्मे मनः शिवसंकल्पमस्तु॥

अचिन्त्यं चाऽप्रमेयं च व्यक्ताऽव्यक्त परं च यत्। सूक्ष्मात् सूक्ष्मतरं ज्ञेयं तन्मे मनः शिवसंकल्पमस्तु॥

एका च दश शतं च सहस्रं चायुतं च नियुतं च प्रयुतं चार्बुदं च न्यर्बुदं च समुद्रश्च मध्यं चान्तश्च परार्धश्च तन्मे मनः शिवसंकल्पमस्तु॥

In Public domain. Digitization Muthulakshmi Research Academy

ये पंच पंचादश शतं सहस्त्रमयुतन्न्यर्बुदं च। ते अग्निचित्येष्टकास्तं शरीरं तन्मे मनः शिवसंकल्पमस्तु॥

वेदाहमेतं पुरुषं महान्तं मादित्यवर्णन्तमसः परस्तात्। यस्य योनिं परिपश्यन्ति धीरास्तन्मे मनः शिवसंकल्पमस्तु॥

यस्येदं धीराः पुनन्ति कवयो ब्रह्माणमेतं त्वा वृणत इन्दुम्। स्थावरं जंगमं द्यौराकाशं तन्मे मनः शिवसंकल्पमस्तु॥

परात्परतरं चैव यत्पराच्चैव यत्परम्। यत्परात्परतो ज्ञेयं तन्मे मनः शिवसंकल्पमस्तु॥

परात्परतरो ब्रह्मा तत्परात्परतो हरिः। तत्परात्परतोऽ-धीशस्तन्मे मनः शिवसंकल्पमस्तु॥

या वेदादिषु गायत्री सर्वव्यापी महेश्वरी। ऋग्यजुस्सा-माथर्वैश्च तन्मे मनः शिवसंकल्पमस्तु॥

यो वै देवं महादेवं प्रणवं परमेश्वरम्। यस्सर्वे सर्ववेदैश्च तन्मे मनः शिवसंकल्पमस्तु॥

प्रयतः प्रणवोङ्कारं प्रणवं पुरुषोत्तमम्। ओंकारं प्रणवात्मानं तन्मे मनः शिवसंकल्पमस्तु॥

योऽसौ सर्वेषु वेदेषु पठ्यते ह्यज ईश्वरः। अकायो निर्गुणोह्यात्मा तन्मे मनः शिवसंकल्पमस्तु॥

गोभिर्जुष्टं धनेन ह्यायुषा च बलेन च। प्रजया पशुभिः पुष्कराक्षं तन्मे मनः शिवसंकल्पमस्तु॥

त्र्यम्बकं यजामहे सुगन्धिं पुष्टिवर्धनम्। उर्वारुकमिव बन्धनान्मृत्योर्मुक्षीय माऽमृतात् तन्मे मनः शिवसंकल्पमस्तु॥

In Public domain. Digitization Muthulakshmi Research Academy

कैलास शिखरे रम्ये शंकरस्य शिवालये। देवतास्तत्र मोदन्ते तन्मे मनः शिवसंकल्पमस्तु॥

विश्वत श्चक्षुरुत विश्वतो मुखो विश्वतो हस्त उत विश्वतस्पात्। संबाहुभ्यान्नमति संपतत्रै द्यावापृथिवी जनयन् देव एकस्तन्मे मनः शिवसंकल्पमस्तु॥

चतुरो वेदानधीयीत सर्वशास्त्रमयं विदुः। इतिहास पुराणानां तन्मे मनः शिवसंकल्पमस्तु॥

मा नो महान्तमुत मा नो अर्भकं मा न उक्षन्त मुत मा न उक्षितम्। मा नो वधीः पितरं मोत मातरं प्रिया मा नस्तनुवो रुद्र रीरिषस्तन्मे मनः शिवसंकल्पमस्तु॥

मा न स्तोके तनये मा न आयुषि मा नो गोषु मा नो अश्वेषु रीरिषः। वीरान्मा नो रुद्र भामितोऽवधीर् हविष्मन्तो नमसा विधेम ते तन्मे मनः शिवसंकल्पमस्तु॥

ऋतꣳ सत्यं परं ब्रह्म पुरुषं कृष्णपिंगलम्। ऊर्ध्वरेतं विरूपाक्षं विश्वरूपाय वै नमो नमस्तन्मे मनः शिवसंकल्पमस्तु॥

कद्रुद्राय प्रचेतसे मीढुष्टमाय तव्यसे। वोचेम शन्तमꣳहृदे। सर्वोह्येष रुद्रस्तस्मै रुद्राय नमो अस्तु तन्मे मनः शिशवसंकल्पमस्तु॥

ब्रह्मजज्ञानं प्रथमं पुरस्ताद्विसीमतस्सुरुचो वेन आवः। स बुध्नियां उपमा अस्य विष्ठास्सतश्च योनि मसतश्च विवस्तन्मे मनः शिवसंकल्पमस्तु॥

यः प्राणतो निमिषतो महित्वैक इद्राजा जगतो बभूव। य ईशे अस्य द्विपदश्चतुष्पदः कस्मै देवाय हविषा विधेम तन्मे मनः शिवसंकल्पमस्तु॥

In Public domain. Digitization Muthulakshmi Research Academy

य आत्मदा बलदा यस्य विश्व उपासते प्रशिषं यस्य देवाः। यस्य छायाऽमृतं यस्य मृत्युः कस्मै देवाय हविषा विधेम तन्मे मनः शिवसंकल्पमस्तु॥

यो रुद्रो अग्नौ यो अप्सु य ओषधीषु यो रुद्रो विश्वा भुवनाऽऽविवेश तस्मै रुद्राय नमो अस्तु तन्मे मनः शिवसंकल्पमस्तु॥

गन्धद्वारां दुराधर्षां नित्यपुष्टां करीषिणीम्। ईश्वरीꣳ सर्वभूतानां तामिहोपह्वये श्रियम् तन्मे मनः शिवसंकल्पमस्तु॥

य इदꣳ शिवसंकल्पꣳ सदा ध्यायन्ति ब्राह्मणाः। ते परं मोक्षं गमिष्यन्ति तन्मे मनः शिवसंकल्पमस्तु॥★ हृदयाय नमः॥

॥ पुरुषसूक्तम् ॥

सहस्रशीर्षा पुरुषः। सहस्राक्षः सहस्रपात्। स भूमिं विश्वतो वृत्वा। अत्यतिष्ठद्दशाङ्गुलम्। पुरुष एवेदꣳ सर्वम्। यद्भूतं यच्च भव्यम्। उतामृतत्त्वस्येशानः। यदन्नेनातिरोहति। एतावानस्य महिमा। अतो ज्यायाꣳश्च पूरुषः। पादोऽस्य विश्वा भूतानि। त्रिपादस्यामृतं दिवि। त्रिपादूर्ध्व उदैत्पुरुषः। पादोऽस्येहाभवात्पुनः। ततो विष्वङ् व्यक्रामत्। साशनानशने अभि। तस्माद्विराडजायत। विराजो अधिपूरुषः। स जातो अत्यरिच्यत।

★ In Ravana Mahanyasam, the following additional mantras are recited :

२६. कैलासशिखरावासा हिमवद्गिरिसंस्थिताम्।
नीलकण्ठं त्रिणेत्रं च तन्मे मनः शिवसंकल्पमस्तु॥

३८. नमकं चमकं चैव पुरुषसूक्तं च यद्विदुः।
महादेवं च तत्तुल्यं तन्मे मनः शिवसंकल्पमस्तु॥

In Public domain. Digitization Muthulakshmi Research Academy

पश्चाद्भूमिमथो पुरः। यत्पुरुषेण हविषा। देवा यज्ञमतन्वत। वसन्तो अस्यासीदाज्यम्। ग्रीष्म इध्मश्शरद्धविः। सप्तास्यासन् परिधयः। त्रिस्सप्तसमिधः कृताः। देवा यद्यज्ञं तन्वानाः। अबध्नन्पुरुषं पशुम्। तं यज्ञं बर्हिषि प्रौक्षन्। पुरुषं जातमग्रतः। तेन देवा अयजन्त। साध्या ऋषयश्च ये। तस्माद्यज्ञात्सर्वहुतः। संभृतं पृषदाज्यम्। पशूꣳस्ताꣳश्चक्रे वायव्यान्। आरण्यान् ग्राम्याश्च ये। तस्माद्यज्ञात्सर्वहुतः। ऋचस्सामानि जज्ञिरे॥ छन्दाꣳसि जज्ञिरे तस्मात्। यजुस्तस्मादजायत। तस्मादश्वा अजायन्त। ये के चोभयादतः। गावो ह जज्ञिरे तस्मात्। तस्माज्जाता अजावयः। यत्पुरुषं व्यदधुः। कतिधा व्यकल्पयन्। मुखं किमस्य कौ बाहू। कावूरू पादा वुच्येते। ब्राह्मणोऽस्य मुखमासीत्। बाहू राजन्यः कृतः। ऊरू तदस्य यद्वैश्यः। पद्भ्याꣳ शूद्रो अजायत। चन्द्रमा मनसो जातः। चक्षोस्सूर्यो अजायत। मुखादिन्द्रश्चाग्निश्च। प्राणाद्वायुरजायत। नाभ्या आसीदन्तरिक्षम्। शीर्ष्णो द्यौस्समवर्तत। पद्भ्यां भूमिर्दिशः श्रोत्रात्। तथा लोकाꣳ अकल्पयन्। वेदाहमेतं पुरुषं महान्तम्। आदित्यवर्णं तमसस्तु पारे। सर्वाणि रूपाणि विचित्य धीरः। नामानि कृत्वाऽभिवदन् यदास्ते। धाता पुरस्ताद्यमुदाजहार। शक्रः प्रविद्वान् प्रदिशश्चतस्रः। तमेवं विद्वानमृत इह भवति। नान्यः पन्था अयनाय विद्यते। यज्ञेन यज्ञमयजन्त देवाः। तानि धर्माणि प्रथमान्यासन्। ते ह नाकं महिमानः सचन्ते। यत्र पूर्वे साध्याः सन्ति देवाः॥

शिरसे स्वाहा॥

In Public domain. Digitization Muthulakshmi Research Academy

॥ उत्तर नारायणम् ॥

अद्भ्यः संभूतः पृथिव्यै रसाँच्च। विश्वकर्मणस्समवर्तताधि। तस्य त्वष्टा विदधद्रूपमेति। तत्पुरुषस्य विश्वमाजानमग्रे। वेदाहमेतं पुरुषं महान्तम्। आदित्यवर्णं तमसः परस्तात्। तमेवं विद्वानमृत इह भवति। नान्यः पन्था विद्यतेऽयनाय। प्रजापतिश्चरति गर्भे अन्तः। अजायमानो बहुधा विजायते। तस्य धीराः परिजानन्ति योनिम्। मरीचीनां पदमिच्छन्ति वेधसः। यो देवेभ्य आतपति। यो देवानां पुरोहितः। पूर्वो यो देवेभ्यो जातः। नमो रुचाय ब्राह्मये। रुचं ब्राह्मं जनयन्तः। देवा अग्रे तदब्रुवन्। यस्त्वैवं ब्राह्मणो विद्यात्। तस्य देवा असन्वशे। ह्रीश्च ते लक्ष्मीश्च पत्न्यौ। अहोरात्रे पार्श्वे। नक्षत्राणि रूपम्। अश्विनौ व्यात्तम्। इष्टं मनिषाण। अमुं मनिषाण। सर्वं मनिषाण॥ शिखायै वषट्॥

॥ अप्रतिरथम् ॥

आशुश्शिशानो वृषभो न युध्मो घनाघनः क्षोभणश्चर्षणीनाम्। संक्रन्दनोऽनिमिष एक वीरश्शतꣳ सेना अजयत्साकमिन्द्रः। संक्रन्दनेनाऽनिमिषेण जिष्णुना युत्कारेण दुश्च्यवनेन धृष्णुना। तदिन्द्रेण जयत तत्सहध्वं युधो नर इषुहस्तेन वृष्णा। स इषुहस्तैः स निषंगिभिर्वशी सꣳस्रष्टा सयुध इन्द्रो गणेन। सꣳसृष्टजित्सोमपा बाहुशर्ध्यूर्ध्वधन्वा प्रतिहिताभिरस्ता। बृहस्पते परिदीया रथेन रक्षोहाऽमित्राꣳ अपबाधमानः। प्रभंजन्त्सेनाः प्रमृणो युधा जयन्नस्माक मेद्ध्यविता

In Public domain. Digitization Muthulakshmi Research Academy

रथानाम्। गोत्रभिदं गोविदं वज्रबाहुं जयन्तमज्म प्रमृणन्त-मोजसा। इमꣳसजाता अनुवीरयध्वमिन्द्रꣳ सखायोऽनु सꣳर-भध्वम्। बलविज्ञायस्स्थविरः प्रवीरस्सहस्वान् वाजी सहमान उग्रः। अभिवीरो अभिसत्वा सहोजा जैत्रमिन्द्र रथमातिष्ठ गोवित्। अभिगोत्राणि सहसा गाहमानोऽदायो वीरश्शत-मन्युरिन्द्रः। दुश्च्यवनः पृतनाषाडयुध्योऽस्माकꣳ सेना अवतु प्रयुत्सु। इन्द्र आसां नेता बृहस्पतिर्दक्षिणा यज्ञः पुर एतु सोमः। देवसेनानामभिभंजतीनां जयन्तीनां मरुतो यन्त्वग्रे। इन्द्रस्य वृष्णो वरुणस्य राज्ञ आदित्यानां मरुताꣳ शर्द्ध उग्रम्। महामनसां भुवनच्यवानां घोषो देवानां जयता मुदस्थात्। अस्माक-मिन्द्रस्समृतेषु ध्वजेष्वस्माकं या इषवस्ता जयन्तु। अस्माकं वीरा उत्तरे भवन्त्वस्मानु देवा अवता हवेषु। उद्धर्षय मघवन्नायुधान्यु-त्सत्वनां मामकानां महाꣳसि। उद्वृत्रहन्वाजिनां वाजिनान्युद्रथानां जयतामेतु घोषः। उपप्रेत जयता नरस्स्थिरावस्सन्तु बाहवः। इन्द्रो वः शर्म यच्छत्वनाधृष्या यथाऽसथ। अवसृष्टा परापत शरव्ये ब्रह्म सꣳशिता। गच्छामित्रान् प्रविश मैषां कंचनोच्छिषः। मर्माणि ते वर्मभिश्छादयामि सोमस्त्वा राजाऽमृतेनाभिवस्ताम्। उरोर्वरीयो वरिवस्ते अस्तु जयन्तं त्वामनु मदन्तु देवाः। यत्र बाणास्संपतन्ति कुमारा विशिखा इव। इन्द्रो नस्तत्र वृत्रहा विश्वाहा शर्म यच्छतु॥ कवचाय हुं॥

In Public domain. Digitization Muthulakshmi Research Academy

॥ प्रतिपूरुषम् ॥

प्रतिपूरुष मेकंकपालान्निर्वपत्येकमतिरिक्तं यावन्तो गृह्यास्स्मस्तेभ्यः कर्मकरं पशूनाꣳ शर्मासि शर्म यजमानस्य शर्म मे यच्छैक एव रुद्रो न द्वितीयाय तस्थ आखुस्ते रुद्र पशुस्तं जुषस्वैष ते रुद्र भागः सह स्वस्राम्बिकया तं जुषस्व भेषजं गवेऽश्वाय पुरुषाय भेषजमथो अस्मभ्यं भेषजꣳ सुभैषजं यथाऽसति। सुगं मेषाय मेष्या अवाम्ब रुद्रमदिमह्यव देवं त्र्यम्बकम्। यथा नः श्रेयसः करद्यथा नो वस्यसः करद्यथानः पशुमतः करद्यथा नो व्यवसाययात्। त्र्यम्बकं यजामहे सुगन्धि पुष्टिवर्द्धनम्। उर्वारुकमिव बन्धनान्मृत्योर्मुक्षीय माऽमृतात्। एषते रुद्र भागस्तं जुषस्व तेनावसेन परो मूजवतो ऽतीह्यवतत धन्वा पिनाकहस्तः कृत्तिवासाः॥

प्रतिपूरुषमेकंकपालान्निर्वपति। जाता एव प्रजा रुद्रान्निरवदयते। एकमतिरिक्तम्। जनिष्यमाणा एव प्रजा रुद्रान्निरवदयते! एककपाला भवन्ति। एकधैव रुद्रं निरवदयते। नाभिघारयति। यदभिघारयेत्। अन्तरवचारिणꣳ रुद्रं कुर्यात्। एकोल्मुकेन यन्ति। (१) तद्धि रुद्रस्य भागधेयम्। इमां दिशं यन्ति। एषा वै रुद्रस्य दिक्। स्वायामेव दिशि रुद्रं निरवदयते। रुद्रो वा अपशुकाया आहुत्यै नातिष्ठत। असौ ते पशुरिति निर्दिशेद्यं द्विष्यात्। यमेव द्वेष्टि। तमस्मै पशुं निर्दिशति। यदि न द्विष्यात्। आखुस्ते पशुरिति ब्रूयात्। (२) न ग्राम्यान् पशून् हिनस्ति। नारण्यान्। चतुष्पथे जुहोति। एष वा अग्नीनां पड्बीशो नाम।

In Public domain. Digitization Muthulakshmi Research Academy

अग्निवत्येव जुहोति। मध्यमेन पर्णेन जुहोति। स्रुग्घ्यैषा। अथो खलु। अन्तमेनैव होतव्यम्। अन्तत एव रुद्रं निरवदयते। (३) एष ते रुद्र भागः सह स्वस्राऽम्बिकयेत्याह। शरद्वा अस्याम्बिका स्वसा। तया वा एष हिनस्ति। यꣳ हिनस्ति। तयैवैनꣳ सह शमयति। भेषजंगव इत्याह। यावन्त एव ग्राम्याः पशवः। तेभ्यो भेषजं करोति। अवाम्ब रुद्रमदिमहीत्याह। आशिषमेवैता- माशास्ते। (४) त्र्यम्बकं यजामह इत्याह। मृत्योर्मुक्षीय माऽमृता- दिति वा वै तदाह। उत्किरन्ति। भगस्य लीप्सन्ते। मूते कृत्वा सजन्ति। यथा जनं यतेऽवसंकरोति। तादृगेव तत्। एष ते रुद्र भाग इत्याह निरवत्त्यै। अप्रतीक्षमायन्ति। अपः परिषिंचति। रुद्रस्यान्तर्हित्यै। प्रवा एतेऽस्माल्लोकाच्च्यवन्ते। ये त्र्यम्बकै- श्चरन्ति। आदित्यं चरुं पुनरेत्य निर्वपति। इयं वा अदितिः। अस्यामेव प्रतितिष्ठन्ति॥५॥ नेत्रत्रयाय वौषट्॥

॥ त्वमग्ने रुद्रोऽनुवाकः॥

त्वमग्ने रुद्रो असुरो महो दिवस्त्वꣳ शर्धो मारुतं पृक्ष ईशिषे। त्वं वातैररुणैर्यासि शंगयस्त्वं पूषा विधतः पासि नुत्मना। आ वो राजानमध्वरस्य रुद्रꣳ होतारꣳ सत्ययज- ꣳरोदस्योः। अग्निं पुरा तनयित्नो रचित्ताद्धिरण्यरूप मवसे कृणुध्वम्। अग्निर्होता निषसादा यजीयानुपस्थे मातुः सुरभावु लोके। युवा कविः पुरुनिष्ठ ऋतावा धर्ताकृष्टीना मुत मध्य इद्धः। साध्वीमकर्देववीतिन्नो अद्य यज्ञस्य जिह्वामविदाम गुह्याम्। स आयुरागात् सुरभिर्वसानो भद्रामकर्देवहूतिं नो अद्य।

In Public domain. Digitization Muthulakshmi Research Academy

अक्रन्ददग्निस्तनयन्निव द्यौः क्षामा रेरिहद्वीरुधः समंजन्। सद्यो जज्ञानो विहीमिद्धो अख्यदा रोदसी भानुना भात्यन्तः। त्वे वसूनि पुर्वणीक होतर्दोषा वस्तो रेरिरे यज्ञियासः। क्षामेव विश्वा भुवनानि यस्मिन्त्सꣳ सौभगानि दधिरे पावके। तुभ्यं ता अंगिरस्तम विश्वाः सुक्षितयः पृथक्। अग्ने कामाय येमिरे। अश्याम तं काममग्ने तवोत्यश्याम रयिꣳ रयिवः सुवीरम्। अश्याम वाजमभिवाजयन्तोश्याम द्युम्नमजरा जरन्ते। श्रेष्ठं यविष्ठ भारताग्ने द्युमन्तमाभर। वसो पुरुस्पृहꣳरयिम्। सश्वितानस्तन्यतू रोचनस्था अजरेभि र्नानदद्भि र्यविष्ठः। यः पावकः पुरुतमः पुरूणि पृथून्यग्नि रनुयाति भर्वन्। आयुष्टे विश्वतो दधदयमग्नि वरेण्यः। पुनस्ते प्राण आयति परा यक्ष्मꣳ सुवामि ते। आयुर्दा अग्ने हविषो जुषाणो घृतप्रतीको घृतयोनिरेधि। घृतं पीत्वा मधु चारु गव्यं पितेव पुत्रमभि रक्षतादिमम्। तस्मै ते प्रतिहर्य ते जातवेदो विचर्षणे। अग्ने जनामि सुष्टुतिम्। दिवस्परि प्रथमं जज्ञे अग्निरस्मद् द्वितीयं परि जातवेदाः। तृतीयमप्सु नृमणा अजस्रमिन्धान एनं जरते स्वाधीः। शुचिः पावक वन्द्योऽग्ने बृहद्विरोचसे। त्वं घृतेभिराहुतः। दृशानो रुक्म उर्व्या व्यद्यौद् दुर्मर्षमायुः श्रिये रुचानः! अग्निरमृतो अभवद्वयोभि र्यदेनं द्यौरजनयत् सुरेताः। आ यदिषे नृपतिं तेज आनट् शुचिरेतो निषिक्तं द्यौरभीके। अग्निः शर्ध मनवद्यं युवानꣳ स्वाधियं जनयत् सूदयच्च। स तेजीयसा मनसा त्वोत उत शिक्ष स्वपत्यस्य शिक्षोः। अग्ने रायो नृतमस्य प्रभूतौ भूयाम ते सुष्टुतयश्च वस्वः। अग्ने सहन्तमाभर द्युम्नस्य प्रासहा रयिम्। विश्वाय

In Public domain. Digitization Muthulakshmi Research Academy

श्चर्षणीरभ्यासा वाजेषु सासहत्। तमग्ने पृतनासहꣳ रयिꣳ सहस्व आभर। त्वꣳहि सत्यो अद्भुतो दाता वाजस्य गोमतः। उक्षान्नाय वशान्नाय सोमपृष्ठाय वेधसे। स्तोमैर्विधेमाग्नये। वद्माहि सूनो अस्यद्म सद्वा चक्रे अग्निर्जनुषा ज्मान्नम्। स त्वन्न ऊर्जसन ऊर्जं धा राजेवजे रवृके क्षेष्यन्तः। अग्न आयूꣳषि पवस आसुवोर्ज मिषं च नः। आरे बाधस्व दुच्छुनाम्। अग्ने पवस्व स्वपा अस्मे वर्चस्सुवीर्यम्। दधत् पोषꣳ रयिं मयि। अग्ने पावक रोचिषा मन्द्रया देवजिह्वया। आ देवान् वक्षि यक्षि च। स नः पावक दीदिवोऽग्ने देवाꣳ इहावह। उप यज्ञꣳ हविश्च नः। अग्निः शुचिव्रततमः शुचिर्विप्रः शुचिः कविः। शुचीरोचत आहुतः। उदग्ने शुचयस्तव शुक्रा भ्राजन्त ईरते। तव ज्योतीꣳष्यर्चयः॥

त्वमग्ने रुद्रो असुरो महो दिवः। त्वꣳ शर्द्धो मारुतं पृक्ष ईशिषे। त्वं वातैररुणैर्यासि शंगयः। त्वं पूषा विधतः पासि नुत्मना। देवा देवेषु श्रयद्ध्वम्। प्रथमा द्वितीयेषु श्रयद्ध्वम्। द्वितीयास्तृतीयेषु श्रयद्ध्वम्। तृतीयाश्चतुर्थेषु श्रयद्ध्वम्। चतुर्थाः पंचमेषु श्रयद्ध्वम्। पंचमाः षष्ठेषु श्रयद्ध्वम्। (१) षष्ठाः सप्तमेषु श्रयद्ध्वम्। सप्तमा अष्टमेषु श्रयद्ध्वम्। अष्टमा नवमेषु श्रयद्ध्वम्। नवमा दशमेषु श्रयद्ध्वम्। दशमा एकादशेषु श्रयद्ध्वम्। एकादशा द्वादशेषु श्रयद्ध्वम्। द्वादशा स्त्रयोदशेषु श्रयद्ध्वम्। त्रयोदशा श्चतुर्दशेषु श्रयद्ध्वम्। चतुर्दशाः पंचदशेषु श्रयद्ध्वम्। पंचदशाः षोडशेषु श्रयद्ध्वम् (२) षोडशाः सप्तदशेषु श्रयद्ध्वम्। सप्तदशा अष्टादशेषु श्रयद्ध्वम्। अष्टादशा एकान्नविꣳशेषु श्रयद्ध्वम्। एकान्नविꣳशा विꣳशेषु

In Public domain. Digitization Muthulakshmi Research Academy

श्रयद्ध्वम्। वि॒ꣳशा एकवि॒ꣳशेषु श्रयद्ध्वम्। ए॒क॒वि॒ꣳशा द्वावि॒ꣳशेषु श्रयद्ध्वम्। द्वावि॒ꣳशा स्त्रयो वि॒ꣳशेषु श्रयद्ध्वम्। त्र॒यो॒वि॒ꣳशा श्चतुर्वि॒ꣳशेषु श्रयद्ध्वम्। च॒तु॒र्वि॒ꣳशाः पंचवि॒ꣳशेषु श्रयद्ध्वम्। पं॒च॒वि॒ꣳशा ष्षड्वि॒ꣳशेषु श्रयद्ध्वम्। (३) ष॒ड्वि॒-ꣳशा स्सप्त वि॒ꣳशेषु श्रयद्ध्वम्। स॒प्त॒वि॒ꣳशा अष्टावि॒ꣳशेषु श्रयद्ध्वम्। अ॒ष्टा॒वि॒ꣳशा एकान्नत्रि॒ꣳशेषु श्रयद्ध्वम्। ए॒का॒न्न॒त्रि॒ꣳशा स्त्रि॒ꣳशेषु श्रयद्ध्वम्। त्रि॒ꣳशा एकत्रि॒ꣳशेषु श्रयद्ध्वम्। ए॒क॒त्रि॒ꣳशा द्वात्रि॒ꣳशेषु श्रयद्ध्वम्। द्वा॒त्रि॒ꣳशा स्त्रयस्त्रि॒ꣳशेषु श्रयद्ध्वम्। देवाँस्त्रिरेकादश॒ा स्त्रिस्त्र-यस्त्रिꣳशाः। उत्तरे भवत। उत्तर वर्त्मान॒ उत्तर सत्त्वानः। यत्काम इ॒दं जु॒होमि। तन्मे॒ समृद्ध्यतां। व॒यꣳस्याम॒ पतयो रयी॒णाम्। भूर्भुव॒स्स्वस्स्वाहा॥ अस्त्राय फट्॥

भूर्भुव॒स्सुव॒रोमिति दिग्बन्धः॥

॥ पञ्चाङ्ग जपः ॥

(१) स॒द्योजा॒तं प्रपद्या॒मि॒ स॒द्योजा॒ताय॒ वै नमो॒ नमः। भ॒वे भ॑वे॒ नातिभवे भवस्व॒ माम्। भ॒वोद्भवाय॒ नमः॥

(२) वा॒मदे॒वाय॒ नमो॒ ज्ये॒ष्ठाय॒ नम श्श्रे॒ष्ठाय॒ नमो रु॒द्राय॒ नम॒ः काला॒य॒ नम॒ः कलविकरणाय॒ नमो॒ बलविकरणाय॒ नमो॒ बला॒य॒ नमो॒ बलप्रमथनाय॒ नम॒ स्सर्वभूतदमनाय॒ नमो म॒नोन्मनाय॒ नमः॥

(३) अ॒घोरे॒भ्योऽथ॒ घोरे॒भ्यो॒ घोर॒घोरतरेभ्यः। सर्वे॒भ्य-

In Public domain. Digitization Muthulakshmi Research Academy

स्सर्वशर्वेभ्यो नमस्ते अस्तु रुद्ररूपेभ्यः ॥

(४) तत्पुरुषाय विद्महे महादेवाय धीमहि। तन्नो रुद्रः प्रचोदयात् ॥

(५) ईशान स्सर्वविद्याना मीश्वर स्सर्वभूतानां ब्रह्माऽधिपति र्ब्रह्मणोऽधिपति र्ब्रह्मा शिवो मे अस्तु सदाशिवोम् ॥

॥ अष्टाङ्ग प्रणामः ॥

हिरण्यगर्भस्समवर्तताग्रे भूतस्य जातः पतिरेक आसीत्। स दाधार पृथिवीं द्यामुतेमां कस्मै देवाय हविषा विधेम ॥ (उरसा) उमामहेश्वराभ्यां नमः ॥

यः प्राणतो निमिषतो महित्वैक इद्राजा जगतो बभूव। य ईशे अस्य द्विपदश्चतुष्पदः कस्मै देवाय हविषा विधेम ॥ (शिरसा) उमामहेश्वराभ्यां नमः ॥

ब्रह्मजज्ञानं प्रथमं पुरस्ताद्विसीमतस्सुरुचो वेन आवः। सबुध्निया उपमा अस्य विष्ठास्सतश्च योनिमसतश्च विवः ॥ (दृष्ट्या) उमामहेश्वराभ्यां नमः ॥

मही द्यौः पृथिवी च न इमं यज्ञं मिमिक्षताम्। पिपृतान्नो भरीमभिः ॥ (मनसा) उमामहेश्वराभ्यां नमः ॥

उपश्वासय पृथिवीमुत द्यां पुरुत्रा ते मनुतां विष्ठितं जगत्। स दुन्दुभे सजूरिन्द्रेण देवैर्दूराद्दवीयो अपसेध शत्रून् ॥ (वचसा) उमामहेश्वराभ्यां नमः ॥

अग्ने नय सुपथा राये अस्मान् विश्वानि देव वयुनानि विद्वान्। युयोध्यस्मज्जुहुराणमेनो भूयिष्ठान्ते नमउक्ति विधेम ॥

In Public domain. Digitization Muthulakshmi Research Academy

(पद्भ्यां) उमामहेश्वराभ्यां नमः ॥

या ते अग्ने रुद्रिया तनूस्तया नः पाहि तस्यास्ते स्वाहा।
(कराभ्यां) उमामहेश्वराभ्यां नमः ॥

इमं यम प्रस्तरमाहि सीदांगिरोभिः पितृभिस्संविदानः। आ त्वा मन्त्राः कविशस्ता वहन्त्वेना राजन् हविषा मादयस्व॥
(कर्णाभ्यां) उमामहेश्वराभ्यां नमः ॥

॥ लघुन्यासः ॥

॥ ध्यानम् ॥

(ओं अथात्मानं शिवात्मानं श्रीरुद्ररूपं ध्यायेत्)
शुद्धस्फटिक संकाशं त्रिणेत्रं पंचवक्त्रकम्।
गंगाधरं दशभुजं सर्वाभरण भूषितम्॥
नीलग्रीवं शशांकांकं नाग यज्ञोपवीतिनम्।
व्याघ्रचर्मोत्तरीयं च वरेण्य मभयप्रदम्॥
कमण्डल्वक्षसूत्राणां धारिणं शूलपाणिनम्।
ज्वलन्तं पिंगलजटं शिखामध्योद धारिणम्॥
वृषस्कन्ध समारूढं उमादेहार्ध धारिणम्।
अमृतेनाप्लुतं शान्तं दिव्यभोग समन्वितम्॥
दिग्देवता-समायुक्तं सुरासुर नमस्कृतम्।
नित्यं च शाश्वतं शुद्धं ध्रुवमक्षर मव्ययम्॥
सर्व व्यापिन-मीशानं रुद्रं वै विश्वरूपिणम्।
एवं ध्यात्वा द्विजस्सम्यक् ततो यजन मारभेत्॥

॥ अङ्ग न्यासः ॥

प्रजनने ब्रह्मा तिष्ठतु। पादयो विंष्णुस्तिष्ठतु। हस्तयो-र्हरस्तिष्ठतु। बाह्वो रिन्द्रस्तिष्ठतु। जठरेअग्निस्तिष्ठतु। हृदये

In Public domain. Digitization Muthulakshmi Research Academy

शिवस्तिष्ठतु। कण्ठे वसवस्तिष्ठन्तु। वक्त्रे सरस्वती तिष्ठतु। नासिकयो र्वायुस्तिष्ठतु। नयनयोश्चन्द्रादित्यौ तिष्ठेताम्। कर्णयोरश्विनौ तिष्ठेताम्। ललाटे रुद्रास्तिष्ठन्तु। मूर्ध्न्यादित्यास्तिष्ठन्तु। शिरसि महादेवस्तिष्ठतु। शिखायां वामदेवस्तिष्ठतु। पृष्ठे पिनाकी तिष्ठतु। पुरतः शूली तिष्ठतु। पार्श्वयोः शिवाशंकरौ तिष्ठेताम्। सर्वतो वायुस्तिष्ठतु। ततो बहिः सर्वतोऽग्निर्ज्वालामाला परिवृतस्तिष्ठतु। सर्वेष्वंगेषु सर्वा देवता यथास्थानं तिष्ठन्तु। मां रक्षन्तु। सर्वान् महाजनान् रक्षन्तु॥

अग्निर्मे॑ वाचि श्रितः। वाग्घृद॑ये। हृद॑यं मयि॑। अहममृते॑। अमृतं ब्रह्म॑णि॥ वायुर्मे॑ प्राणे श्रितः। प्राणो हृद॑ये। हृद॑यं मयि॑। अहममृते॑। अमृतं ब्रह्म॑णि॥ सूर्यो॑ मे चक्षुषि श्रितः। चक्षुर्हृद॑ये। हृद॑यं मयि॑। अहममृते॑। अमृतं ब्रह्म॑णि॥ चन्द्रमा॑ मे मन॑सि श्रितः। मनो हृद॑ये। हृद॑यं मयि॑। अहममृते॑। अमृतं ब्रह्म॑णि॥ दिशो॑ मे श्रोत्रे॑ श्रिताः। श्रोत्रꣳ हृद॑ये। हृद॑यं मयि॑। अहममृते॑। अमृतं ब्रह्म॑णि॥ आपो॑ मे रेत॑सि श्रिताः। रेतो हृद॑ये। हृद॑यं मयि॑। अहममृते॑। अमृतं ब्रह्म॑णि॥ पृथिवी मे शरी॑रे श्रिता। शरी॑रꣳ हृद॑ये। हृद॑यं मयि॑। अहममृते॑। अमृतं ब्रह्म॑णि॥ ओषधिवनस्पतयो॑ मे लोम॑सु श्रिताः। लोमा॑नि हृद॑ये। हृद॑यं मयि॑। अहममृते॑। अमृतं ब्रह्म॑णि॥ इन्द्रो॑ मे बले॑ श्रितः। बलꣳ हृद॑ये। हृद॑यं मयि॑। अहममृते॑। अमृतं ब्रह्म॑णि॥ पर्जन्यो॑ मे मूर्ध्नि श्रितः। मूर्धा हृद॑ये। हृद॑यं मयि॑। अहममृते॑। अमृतं ब्रह्म॑णि॥ ईशा॑नो मे मन्यौ श्रितः। मन्युर्हृद॑ये। हृद॑यं मयि॑। अहममृते॑। अमृतं ब्रह्म॑णि॥ आत्मा म॑ आत्मनि॑ श्रितः। आत्मा हृद॑ये। हृद॑यं मयि॑। अहममृते॑। अमृतं ब्रह्म॑णि॥

In Public domain. Digitization Muthulakshmi Research Academy

पुनर्मे आत्मा पुनरायुरागात्। पुनः प्राणः पुनराकूत मागात्। वैश्वानरो रश्मिभिर्वा वृधानः। अन्तस्तिष्ठत्वमृतस्य गोपाः॥ आराधितो मनुष्यैस्त्वं सिद्धै देवा सुरादिभिः। आराधयामि भक्त्या त्वां मां गृहाण महेश्वर॥

॥ कलशेषु ध्यानम् ॥

ध्यायेन्निरामयं वस्तु सर्गस्थिति लयाधिकम्।
निर्गुणं निष्कलं नित्यं मनोवाचामगोचरम्॥
गंगाधरं शशिधरं जटामकुट शोभितम्।
श्वेतभूति त्रिपुण्ड्रेण विराजित ललाटकम्॥
लोचनत्रय संपन्नं स्वर्णकुण्डल शोभितम्।
स्मेराननं चतुर्बाहुं मुक्ताहारोप शोभितम्॥
अक्षमालां सुधाकुंभं चिन्मयीं मुद्रिकामपि।
पुस्तकं च भुजै र्दिव्यै र्दधानं पार्वतीपतिम्॥
श्वेताम्बरधरं श्वेतं रत्नसिंहासन स्थितम्।
सर्वाभीष्ट प्रदातारं वटमूल निवासिनम्॥
वामाङ्के संस्थितां गौरीं बालार्कायुत सन्निभाम्।
जपाकुसुम साहस्त्र समान श्रिय मीश्वरीम्।
सुवर्ण रत्नखचित मकुटेन विराजिताम्॥
ललाटपट्टसंराजत् संलग्न तिलकांचिताम्।
राजीवायत नेत्रान्तां नीलोत्पलदलेक्षणाम्॥
सन्तप्त हेमरचित ताटंकाभरणान्विताम्।
ताम्बूल चर्वण रत रक्तजिह्वाविराजिताम्॥
पताकाभरणोपेतां मुक्ताहारोपशोभिताम्।
स्वर्णकंकण संयुक्तै श्चतुर्भि र्बाहुभि र्युताम्॥
सुवर्णरत्नखचित कांचीदाम विराजिताम्।

In Public domain. Digitization Muthulakshmi Research Academy

कदलीललितस्तम्भ सन्निभोरु युगान्विताम्॥
श्रिया विराजितपदां भक्तत्राण परायणाम्।
अन्योन्याश्लिष्टहृद्बाहु गौरीशंकर संज्ञकम्॥
सनातनं परं ब्रह्म परमात्मान मव्ययम्।
आवाहयामि जगता मीश्वरं परमेश्वरम्॥

आ त्वा वहन्तु हरयस्सचेतसः श्वेतैरश्वैस्सह केतुमद्भिः। वाताजितै र्बलवद्भि र्मनोजवै रायाहि शीघ्रं मम हव्याय शर्वोम्॥ त्र्यम्बकं यजामहे सुगन्धिं पुष्टिवर्धनम्। उर्वारुकमिव बन्धनान्मृत्योर्मुक्षीय माऽमृतात्॥ गौरी मिमाय सलिलानि तक्षत्येकपदी द्विपदी सा चतुष्पदी। अष्टापदी नवपदी बभूवुषी सहस्राक्षरा परमे व्योमन्॥

॥ आवाहनः ॥

ओं नमस्ते रुद्रमन्यव उतो त इषवे नमः। नमस्ते अस्तु धन्वने बाहुभ्यामुत ते नमः॥ ओं ह्रीं नमः शिवाय। सद्योजातं प्रपद्यामि। ओं भूर्भुवस्सुवरों। अस्मिन् कुम्भे (अस्यां प्रतिमायां) (धी देवी समेत) महादेवं ध्यायामि। आवाहयामि॥ (वृत्ति देवी समेत) शिवं ध्यायामि। आवाहयामि॥ (उशना देवी समेत) रुद्रं ध्यायामि। आवाहयामि॥ (उमा देवी समेत) शंकरं ध्यायामि। आवाहयामि॥ (नियुद्देवी समेत) नीललोहितं ध्यायामि। आवाहयामि॥ (सर्पि र्देवी समेत) ईशानं ध्यायामि। आवाहयामि॥ (इळा देवी समेत) विजयं ध्यायामि। आवाहयामि॥ (अंबिका देवी समेत) भीमं ध्यायामि। आवाहयामि॥ (इरावती देवी समेत) देवदेवं ध्यायामि। आवाहयामि॥ (सुधा देवी समेत) भवं ध्यायामि। आवाहयामि॥ (दीक्षा देवी समेत) उद्भवं ध्यायामि। आवाहयामि॥

In Public domain. Digitization Muthulakshmi Research Academy

आदित्यात्मक रुद्रं ध्यायामि। आवाहयामि॥ (इति तत्तत् कलशेषु आवाह्य)॥

॥ प्राणप्रतिष्ठा ॥

आदित्यात्मक श्रीमहादेवादि प्राणप्रतिष्ठा महामन्त्रस्य, ब्रह्म विष्णु महेश्वरा ऋषयः। ऋग्यजुस्सामाथर्वाणि छन्दांसि। सकलजगत्सृष्टि स्थिति संहार कारिणी प्राणशक्तिः परादेवता। आं—बीजम्। ह्रीं—शक्तिः। क्रों—कीलकम्। आदित्यात्मक महादेवादि प्राणप्रतिष्ठार्थे जपे विनियोगः॥

आं—अंगुष्ठाभ्यां नमः। ह्रीं—तर्जनीभ्यां नमः। क्रों—मध्यमाभ्यां नमः। आं—अनामिकाभ्यां नमः। ह्रीं—कनिष्ठिकाभ्यां नमः। क्रों—करतलकरपृष्ठाभ्यां नमः॥

आं—हृदयाय नमः। ह्रीं—शिरसे स्वाहा। क्रों—शिखायै वषट्। आं—कवचाय हुं। ह्रीं—नेत्रत्रयाय वौषट्। क्रों—अस्त्राय फट्। भूर्भुवस्सुवरोमिति दिग्बन्धः॥

॥ ध्यानम्॥

रक्ताम्भोधिस्थ पोतोल्लस दरुण सरोजाधिरूढा कराब्जैः, पाशं कोदण्डमिक्षूद्भव मळिगुण मप्यंकुशं पंचबाणान्।

बिभ्राणासृक्कपालं त्रिनयन लसिता पीनवक्षोरुहाढ्या, देवी बालार्कवर्णा भवतु सुखकरी प्राणशक्तिः परा नः॥

लं—पृथिव्यात्मिकायै गन्धं समर्पयामि। हं—आकाशात्मिकायै पुष्पैः पूजयामि। यं—वाय्वात्मिकायै धूपमाघ्रापयामि। रं—अग्न्यात्मिकायै दीपं दर्शयामि। वं— अमृतात्मिकायै अमृतं महानैवेद्यं निवेदयामि। सं—सर्वात्मिकायै सर्वोपचार पूजां समर्पयामि॥

In Public domain. Digitization Muthulakshmi Research Academy

आं-ह्रीं-क्रों, क्रों-ह्रीं-आं यरलवशषसहों। क्षं हंसः सोऽहं, सोऽहं हंसः। आदित्यात्मक महादेवादि प्राणा इह प्राणाः॥

आं-ह्रीं-क्रों, क्रों-ह्रीं आं यरलवशषसहों। क्षं हंसः सोऽहं, सोऽहं हंसः। आदित्यात्मक महादेवादि जीव इह स्थितः॥

आं-ह्रीं-क्रों, क्रों-ह्रीं-आं यरलवशषसहों। हंसः सोऽहं, सोऽहं हंसः। आदित्यात्मक महादेवादि सर्वेन्द्रियाणि वाङ्मनश्चक्षुश्श्रोत्र जिह्वा घ्राण प्राणापान व्यानोदान समाना इहैवागत्य इहैवास्मिन् कुम्भे सुखं चिरं तिष्ठन्तु स्वाहा॥

असुनीते पुनरस्मासु चक्षुः पुनः प्राणमिह नो धेहि भोगम्। ज्योक् पश्येम सूर्यमुच्चरन्त मनुमते मृडया नस्स्वस्ति॥

आवाहितो भव। स्थापितो भव। सन्निहितो भव। सन्निरुद्धो भव। अवकुण्ठितो भव। सुप्रीतो भव। सुप्रसन्नो भव। वरदो भव। प्रसीद प्रसीद॥ स्वामिन् सर्वजगन्नाथ यावत्पूजावसानकम्। तावत्त्वं प्रीतिभावेन कुम्भेऽस्मिन् सन्निधिं कुरु॥ आदित्यात्मक महादेवादि प्राणान् प्रतिष्ठापयामि॥ (पंचोपचार पूजा॥ त्रिमधुरंनिवेदयामि॥) पंचादश संस्कारार्थे पंचादश ओंकारजपम् करिष्ये। (प्रणव जपं कृत्त्वा)

॥ आसनादि उपचाराः ॥

रत्न सिंहासनम्—या त इषुः शिवतमा शिवं बभूव ते धनुः। शिवा शरव्या या तव तया नो रुद्र मृडय॥ ओं ह्रीं नमः शिवाय। सद्योजाताय वै नमो नमः। रत्नसिंहासनं समर्पयामि॥

पाद्यम्—या ते रुद्र शिवा तनूरघोराऽपाप काशिनी। तया नस्तनुवा शन्तमया गिरिशन्ताभिचाकशीहि॥ ओं ह्रीं नमः

In Public domain. Digitization Muthulakshmi Research Academy

शिवाय। भवे भवे नातिभवे भवस्व माम्। पादयोः पाद्यं समर्पयामि॥

अर्घ्यम्—यामिषुं गिरिशन्त हस्ते बिभर्ष्यस्तवे। शिवां गिरित्र तां कुरु मा हिंसीः पुरुषं जगत्। ओं ह्रीं नमः शिवाय। भवोद्भवाय नमः। अर्घ्यं समर्पयामि॥

आचमनीयम्—शिवेन वचसा त्वा गिरिशाच्छा वदामसि। यथा नः सर्वमिज्जगदयक्ष्मं सुमना असत्। ओं ह्रीं नमः शिवाय। वामदेवाय नमः। आचमनीयं समर्पयामि॥

मधुपर्कः—अध्यवोचदधिवक्ता प्रथमो दैव्यो भिषक्। अहीँश्च सर्वाञ्जम्भयन्थ्सर्वाश्च यातुधान्यः। ओं ह्रीं नमः शिवाय। ज्येष्ठाय नमः। मधुपर्कं समर्पयामि॥

स्नानम्—असौ यस्ताम्रो अरुण उत बभ्रुस्सुमंगलः। ये चेमाꣳरुद्रा अभितो दिक्षु श्रितास्सहस्त्रशोऽवैषाꣳ हेडं ईमहे। ओं ह्रीं नमः शिवाय। श्रेष्ठाय नमः। स्नानं समर्पयामि। स्नानानन्तरं आचमनीयं समर्पयामि॥

वस्त्रं—असौ योऽवसर्पति नीलग्रीवो विलोहितः। उतैनं गोपा अदृशन्नदृशन्नुदहार्यः। उतैनं विश्वा भूतानि स दृष्टो मृडयाति नः। ओं ह्रीं नमः शिवाय। रुद्राय नमः। वस्त्रोत्तरीयं समर्पयामि॥

यज्ञोपवीतं—नमो अस्तु नीलग्रीवाय सहस्त्राक्षाय मीढुषे। अथो ये अस्य सत्वानोऽहं तेभ्योऽकरन्नमः। ओं ह्रीं नमः शिवाय। कालाय नमः। यज्ञोपवीताभरणानि समर्पयामि॥

In Public domain. Digitization Muthulakshmi Research Academy

गन्धं—प्रमुंच धन्वनस्त्व मुभयोरार्त्नियोर्ज्याम्। याश्च ते हस्त इषवः परा ता भगवो वप। ओं ह्रीं नमः शिवाय। बलविकरणाय नमः। गन्धान् धारयामि। गन्धस्योपरि अक्षतान् (हरिद्रा कुंकुमम्) समर्पयामि॥

पुष्पं—अवतत्य धनुस्त्वꣳ सहस्राक्ष शतेषुधे। निशीर्य शल्यानां मुखा शिवो नः सुमना भव। ओं ह्रीं नमः शिवाय। बलविकरणाय नमः। पुष्पैः पूजयामि।

॥ अर्चना ॥

ओं भवाय देवाय नमः। शर्वाय देवाय नमः। ईशानाय देवाय नमः। पशुपतये देवाय नमः। रुद्राय देवाय नमः। उग्राय देवाय नमः। भीमाय देवाय नमः। महते देवाय नमः॥

ओं भवस्य देवस्य पत्न्यै नमः। शर्वस्य देवस्य पत्न्यै नमः। ईशानस्य देवस्य पत्न्यै नमः। पशुपतेः देवस्य पत्न्यै नमः। रुद्रस्य देवस्य पत्न्यै नमः। उग्रस्य देवस्य पत्न्यै नमः। भीमस्य देवस्य पत्न्यै नमः। महतो देवस्य पत्न्यै नमः॥

निधनपतये नमः। निधनपतान्तिकाय नमः। ऊर्ध्वाय नमः। ऊर्ध्वलिंगाय नमः। हिरण्याय नमः। हिरण्यलिंगाय नमः। सुवर्णाय नमः। सुवर्णलिंगाय नमः। दिव्याय नमः। दिव्यलिंगाय नमः। भवाय नमः। भवलिंगाय नमः। शर्वाय नमः। शर्वलिंगाय नमः। शिवाय नमः। शिवलिंगाय नमः। ज्वलाय नमः। ज्वललिंगाय नमः। आत्माय नमः। आत्मलिंगाय नमः। परमाय नमः। परमलिंगाय नमः। एतत्सोमस्य सूर्यस्य सर्वलिंगꣳ स्थापयति पाणिमन्त्रं पवित्रम्॥

In Public domain. Digitization Muthulakshmi Research Academy

॥ शिवाष्टोत्तरशत-नामावळिः ॥

ॐ शिवाय नमः
ॐ महेश्वराय नमः
ॐ शंभवे नमः
ॐ पिनाकिने नमः
ॐ शशिशेखराय नमः
ॐ वामदेवाय नमः
ॐ विरूपाक्षाय नमः
ॐ कपर्दिने नमः
ॐ नीललोहिताय नमः
ॐ शंकराय नमः (१०)
ॐ शूलपाणये नमः
ॐ खट्वांगिने नमः
ॐ विष्णुवल्लभाय नमः
ॐ शिपिविष्टाय नमः
ॐ अंबिकानाथाय नमः
ॐ श्रीकण्ठाय नमः
ॐ भक्तवत्सलाय नमः
ॐ भवाय नमः
ॐ शर्वाय नमः
ॐ त्रिलोकेशाय नमः (२०)
ॐ शितिकण्ठाय नमः
ॐ शिवाप्रियाय नमः
ॐ उग्राय नमः
ॐ कपर्दिने नमः
ॐ कामारये नमः
ॐ अन्धकासुर सूदनाय नमः
ॐ गङ्गाधराय नमः
ॐ ललाटाक्षाय नमः
ॐ कालकालाय नमः
ॐ कृपानिधये नमः (३०)
ॐ भीमाय नमः
ॐ परशुहस्ताय नमः
ॐ मृगपाणये नमः
ॐ जटाधराय नमः
ॐ कैलासवासिने नमः
ॐ कवचिने नमः
ॐ कठोराय नमः
ॐ त्रिपुरान्तकाय नमः
ॐ वृषांकाय नमः
ॐ वृषभारूढाय नमः (४०)
ॐ भस्मोद्धूलित विग्रहाय नमः
ॐ सामप्रियाय नमः
ॐ स्वरमयाय नमः
ॐ त्रयीमूर्तये नमः
ॐ अनीश्वराय नमः
ॐ सर्वज्ञाय नमः

In Public domain. Digitization Muthulakshmi Research Academy

ॐ परमात्मने नमः
ॐ सोमसूर्याग्निलोचनाय नमः
ॐ हविषे नमः
ॐ यज्ञमयाय नमः (५०)
ॐ सोमाय नमः
ॐ पंचवक्त्राय नमः
ॐ सदाशिवाय नमः
ॐ विश्वेश्वराय नमः
ॐ वीरभद्राय नमः
ॐ गणनाथाय नमः
ॐ प्रजापतये नमः
ॐ हिरण्यरेतसे नमः
ॐ दुर्धर्षाय नमः
ॐ गिरीशाय नमः (६०)
ॐ गिरिशाय नमः
ॐ अनघाय नमः
ॐ भुजङ्गभूषणाय नमः
ॐ भर्गाय नमः
ॐ गिरिधन्वने नमः
ॐ गिरिप्रियाय नमः
ॐ कृत्तिवाससे नमः
ॐ पुरारातये नमः
ॐ भगवते नमः
ॐ प्रमथाधिपाय नमः (७०)
ॐ मृत्युंजयाय नमः
ॐ सूक्ष्मतनवे नमः
ॐ जगद्व्यापिने नमः
ॐ जगद्गुरवे नमः
ॐ व्योमकेशाय नमः
ॐ महासेनजनकाय नमः
ॐ चारुविक्रमाय नमः
ॐ रुद्राय नमः
ॐ भूतपतये नमः
ॐ स्थाणवे नमः (८०)
ॐ अहिर्बुध्न्याय नमः
ॐ दिगंबराय नमः
ॐ अष्टमूर्तये नमः
ॐ अनेकात्मने नमः
ॐ सात्विकाय नमः
ॐ शुद्धविग्रहाय नमः
ॐ शाश्वताय नमः
ॐ खण्डपरशवे नमः
ॐ अजाय नमः
ॐ पाशविमोचकाय नमः (९०)
ॐ मृडाय नमः
ॐ पशुपतये नमः
ॐ देवाय नमः
ॐ महादेवाय नमः

In Public domain. Digitization Muthulakshmi Research Academy

ॐ अव्ययाय नमः
ॐ हरये नमः
ॐ भगनेत्रभिदे नमः
ॐ अव्यक्ताय नमः
ॐ दक्षाध्वरहराय नमः
ॐ हराय नमः (१००)
ॐ पूषदन्तभिदे नमः
ॐ अव्यग्राय नमः
ॐ सहस्राक्षाय नमः
ॐ सहस्रपदे नमः
ॐ अपवर्गप्रदाय नमः
ॐ अनन्ताय नमः
ॐ तारकाय नमः
ॐ परमेश्वराय नमः (१०८)

॥ श्री गणेश अष्टोत्तरशतनामावळिः ॥ (१)

ॐ गजाननाय नमः
ॐ गणाध्यक्षाय नमः
ॐ विघ्नराजाय नमः
ॐ विनायकाय नमः
ॐ द्वैमातुराय नमः
ॐ सुमुखाय नमः
ॐ प्रमुखाय नमः
ॐ सन्मुखाय नमः
ॐ कृतिने नमः
ॐ ज्ञानदीपाय नमः (१०)
ॐ सुखनिधये नमः
ॐ सुराध्यक्षाय नमः
ॐ सुरारिभिदे नमः
ॐ महागणपतये नमः
ॐ मान्याय नमः
ॐ महन्मान्याय नमः
ॐ मृडात्मजाय नमः
ॐ पुराणाय नमः
ॐ पुरुषाय नमः
ॐ पूष्णे नमः(२०)
ॐ पुष्करिणे नमः
ॐ पुण्यकृते नमः
ॐ अग्रगण्याय नमः
ॐ अग्रपूज्याय नमः
ॐ अग्रगामिने नमः
ॐ मन्त्रकृते नमः
ॐ चामीकरप्रभाय नमः
ॐ सर्वस्मै नमः
ॐ सर्पोपास्याय नमः
ॐ सर्वकर्त्रे नमः(३०)
ॐ सर्वनेत्रे नमः
ॐ सर्व सिद्धिप्रदाय नमः

In Public domain. Digitization Muthulakshmi Research Academy

ॐ सर्व सिद्धाय नमः
ॐ सर्ववन्द्याय नमः
ॐ महाकाळाय नमः
ॐ महाबलाय नमः
ॐ हेरम्बाय नमः
ॐ लम्बजठराय नमः
ॐ ह्रस्वग्रीवाय नमः
ॐ महोदराय नमः(४०)
ॐ मदोत्कटाय नमः
ॐ महावीराय नमः
ॐ मन्त्रिणे नमः
ॐ मंगळदाय नमः
ॐ प्रमथार्च्याय नमः
ॐ प्राज्ञाय नमः
ॐ प्रमोदाय नमः
ॐ मोदक प्रियाय नमः
ॐ धृतिमते नमः
ॐ मतिमते नमः(५०)
ॐ कामिने नमः
ॐ कपित्थप्रियाय नमः
ॐ ब्रह्मचारिणे नमः
ॐ ब्रह्मरूपिणे नमः
ॐ ब्रह्मविदे नमः
ॐ ब्रह्मवन्दिताय नमः
ॐ जिष्णवे नमः
ॐ विष्णुप्रियाय नमः
ॐ भक्तजीविताय नमः

ॐ जितमन्मथाय नमः (६०)
ॐ ऐश्वर्यदाय नमः
ॐ गुहज्यायसे नमः
ॐ सिद्धसेविताय नमः
ॐ विघ्नहर्त्रे नमः
ॐ विघ्नकर्त्रे नमः
ॐ विश्वनेत्रे नमः
ॐ विराजे नमः
ॐ स्वराजे नमः
ॐ श्रीपतये नमः
ॐ वाक्पतये नमः (७०)
ॐ श्रीमते नमः
ॐ श्रृंगारिणे नमः
ॐ श्रितवत्सलाय नमः
ॐ शिवप्रियाय नमः
ॐ शीघ्रकारिणे नमः
ॐ शाश्वताय नमः
ॐ शिवनन्दनाय नमः
ॐ बलोद्धताय नमः
ॐ भक्तनिधये नमः
ॐ भावगम्याय नमः (८०)
ॐ भवात्मजाय नमः
ॐ महते नमः
ॐ मंगळदायिने नमः
ॐ महेशाय नमः
ॐ महिताय नमः
ॐ सत्यधर्मिणे नमः

In Public domain. Digitization Muthulakshmi Research Academy

ॐ सदाधाराय नमः
ॐ सत्याय नमः
ॐ सत्यपराक्रमाय नमः
ॐ शुभांगाय नमः (९०)
ॐ शुभ्रदन्ताय नमः
ॐ शुभदाय नमः
ॐ शुभविग्रहाय नमः
ॐ पञ्चपातकनाशिने नमः
ॐ पार्वतीप्रियनन्दनाय नमः
ॐ विश्वेशाय नमः
ॐ विबुधाराध्यपदाय नमः
ॐ वीरवराग्रगाय नमः
ॐ कुमार गुरुवन्द्याय नमः
ॐ कुञ्जरासुरभञ्जनाय नमः (१००)
ॐ वल्लभावल्लभाय नमः
ॐ वराभयकराम्बुजाय नमः
ॐ सुधा कलश हस्ताय नमः
ॐ सुधाकर कलाधराय नमः
ॐ पञ्चहस्ताय नमः
ॐ प्रधानेशाय नमः
ॐ पुरातनाय नमः
ॐ वरसिद्धिविनायकाय नमः(१०८)

॥ श्री विनायक अष्टोत्तर शतनामावळिः ॥ (२)

ॐ विनायकाय नमः
ॐ विघ्नराजाय नमः
ॐ गौरीपुत्राय नमः
ॐ गणेश्वराय नमः
ॐ स्कन्दाग्रजाय नमः
ॐ अव्ययाय नमः
ॐ पूताय नमः
ॐ दक्षाय नमः
ॐ अध्यक्षाय नमः
ॐ द्विजप्रियाय नमः (१०)
ॐ अग्निगर्भच्छिदे नमः
ॐ इन्द्रश्रीप्रदाय नमः
ॐ वाणीप्रदाय नमः
ॐ सर्वसिद्धिप्रदाय नमः
ॐ शर्वतनयाय नमः
ॐ शर्वरीप्रियाय नमः
ॐ सर्वात्मकाय नमः
ॐ सृष्टिकर्त्रे नमः
ॐ देवाय नमः
ॐ अनेकार्चिताय नमः (२०)
ॐ शिवाय नमः
ॐ सिद्धिबुद्धिप्रदाय नमः
ॐ शान्ताय नमः
ॐ ब्रह्मचारिणे नमः

In Public domain. Digitization Muthulakshmi Research Academy

ॐ गजाननाय नमः
ॐ द्वैमातुराय नमः
ॐ मुनिस्तुत्याय नमः
ॐ भक्तविघ्नविनाशनाय नमः
ॐ एकदन्ताय नमः
ॐ चतुर्बाहवे नमः (३०)
ॐ चतुराय नमः
ॐ शक्तिसंयुताय नमः
ॐ लम्बोदराय नमः
ॐ शूर्पकर्णाय नमः
ॐ हरये नमः
ॐ ब्रह्मविदुत्तमाय नमः
ॐ कालाय नमः
ॐ ग्रहपतये नमः
ॐ कामिने नमः
ॐ सोमसूर्याग्निलोचनाय नमः (४०)
ॐ पाशांकुशधराय नमः
ॐ चण्डाय नमः
ॐ गुणातीताय नमः
ॐ निरञ्जनाय नमः
ॐ अकल्मषाय नमः
ॐ स्वयंसिद्धाय नमः
ॐ सिद्धार्चितपदाम्बुजाय नमः
ॐ बीजापूरफलासक्ताय नमः
ॐ वरदाय नमः
ॐ शाश्वताय नमः (५०)
ॐ कृतिने नमः
ॐ द्विजप्रियाय नमः
ॐ वीतभयाय नमः
ॐ गदिने नमः
ॐ चक्रिणे नमः
ॐ इक्षुचापधृते नमः
ॐ श्रीदाय नमः
ॐ अजाय नमः
ॐ उत्पलकराय नमः
ॐ श्रीपतिस्तुतिहर्षिताय नमः (६०)
ॐ कुलाद्रिभेत्रे नमः
ॐ जटिलाय नमः
ॐ चन्द्रचूडामणये नमः
ॐ अमरेश्वराय नमः
ॐ नागयज्ञोपवीतिने नमः
ॐ कलिकल्मषनाशनाय नमः
ॐ स्थूलकण्ठाय नमः
ॐ स्वयंकर्त्रे नमः
ॐ सामघोषप्रियाय नमः
ॐ पराय नमः (७०)
ॐ स्थूलतुण्डाय नमः
ॐ अग्रण्ये नमः

In Public domain. Digitization Muthulakshmi Research Academy

ॐ धीराय नमः
ॐ वागीशाय नमः
ॐ सिद्धिदायकाय नमः
ॐ दूर्वाबिल्वप्रियाय नमः
ॐ कान्ताय नमः
ॐ पापहारिणे नमः
ॐ समाहिताय नमः
ॐ आश्रितश्रीकराय नमः (८०)
ॐ सौम्याय नमः
ॐ भक्तवाञ्छितदायकाय नमः
ॐ शान्ताय नमः
ॐ अच्युतार्च्याय नमः
ॐ कैवल्याय नमः
ॐ सच्चिदानन्दविग्रहाय नमः
ॐ ज्ञानिने नमः
ॐ दयायुताय नमः
ॐ दान्ताय नमः
ॐ ब्रह्मद्वेषविवर्जिताय नमः (९०)
ॐ प्रमत्तदैत्यभयदाय नमः
ॐ व्यक्तमूर्तये नमः
ॐ शैलेन्द्रतनयोत्सङ्गखेलनो-त्सुक मानसाय नमः
ॐ शंकरोत्सङ्गसततखेलनो-त्सुकमानसाय नमः
ॐ समस्तजगदाधाराय नमः
ॐ मायिने नमः
ॐ मूषिकवाहनाय नमः
ॐ चन्द्रचूडामणये नमः
ॐ कान्ताय नमः
ॐ पापहारिणे नमः (१००)
ॐ समाहिताय नमः
ॐ चिन्तामणिद्वीपपतये नमः
ॐ परमात्मने नमः
ॐ गजाननाय नमः
ॐ हृष्टाय नमः
ॐ तुष्टाय नमः
ॐ प्रसन्नात्मने नमः
ॐ सर्वसिद्धिप्रदायकाय नमः (१०८)

॥ श्री विनायक अष्टोत्तरशतनामावळिः संपूर्णः ॥

★★★

In Public domain. Digitization Muthulakshmi Research Academy

॥ श्री आञ्जनेय अष्टोत्तरशतनामावळिः ॥

ॐ आञ्जनेयाय नमः
ॐ महावीराय नमः
ॐ हनुमते नमः
ॐ मारुतात्मजाय नमः
ॐ तत्वज्ञान प्रदाय नमः
ॐ सीतादेवी मुद्राप्रदायकाय नमः
ॐ अशोक वनिकाच्छेत्रे नमः
ॐ सर्वमाया विभञ्जनाय नमः
ॐ सर्वबन्ध विमोक्त्रे नमः
ॐ रक्षोविध्वंस कारकाय नमः(१०)
ॐ परविद्यापरीहाराय नमः
ॐ परशौर्य विनाशनाय नमः
ॐ परमन्त्र निराकर्त्रे नमः
ॐ परयन्त्र प्रभेदकाय नमः
ॐ सर्वग्रह विनाशिने नमः
ॐ भीमसेन सहायकृते नमः
ॐ सर्व दुःख हराय नमः
ॐ सर्व लोकसंचारिणे नमः
ॐ मनोजवाय नमः
ॐ पारिजात द्रुमूलस्थाय नमः(२०)
ॐ सर्वमन्त्र स्वरूपवते नमः
ॐ सर्वयन्त्र स्वरूपिणे नमः
ॐ सर्वतन्त्रात्मकाय नमः
ॐ कपीश्वराय नमः
ॐ महाकायाय नमः
ॐ सर्वरोग हराय नमः
ॐ प्रभवे नमः
ॐ फलसिद्धिकराय नमः
ॐ सर्वविद्यासम्पत्प्रदायकाय नमः
ॐ कपिसेना नायकाय नमः(३०)
ॐ भविष्यत् चतुराननाय नमः
ॐ कुमार ब्रह्मचारिणे नमः
ॐ रत्नकुण्डल दीप्तिमते नमः
ॐ सञ्चलद्वाल सन्नद्ध लंबमान शिखोज्ज्वलाय नमः
ॐ गन्धर्व विद्यातत्वज्ञाय नमः
ॐ महाबल पराक्रमाय नमः
ॐ कारागृह विमोक्त्रे नमः
ॐ श्रृंखला बन्धमोचकाय नमः
ॐ सागरोत्तारकाय नमः
ॐ प्राज्ञाय नमः (४०)
ॐ रामदूताय नमः
ॐ प्रतापवते नमः
ॐ वानराय नमः
ॐ केसरी सुताय नमः
ॐ सीताशोक निवारणाय नमः
ॐ अञ्जनागर्भ संभूताय नमः
ॐ बालार्क सदृशाननाय नमः

In Public domain. Digitization Muthulakshmi Research Academy

ॐ विभीषण प्रियकराय नमः
ॐ दशग्रीव कुलान्तकाय नमः
ॐ लक्ष्मण प्राणदात्रे नमः (५०)
ॐ वज्रकायाय नमः
ॐ महाद्युतये नमः
ॐ चिरञ्जीविने नमः
ॐ रामभक्ताय नमः
ॐ दैत्यकार्य विघातकाय नमः
ॐ अक्षहंत्रे नमः
ॐ काञ्चनाभाय नमः
ॐ पञ्चवक्त्राय नमः
ॐ महातपसे नमः
ॐ लंकिणी भञ्जनाय नमः (६०)
ॐ श्रीमते नमः
ॐ सिंहिका प्राण भञ्जनाय नमः
ॐ गन्धमादन शैलस्थाय नमः
ॐ लंकापुर विदाहकाय नमः
ॐ सुग्रीव सचिवाय नमः
ॐ धीराय नमः
ॐ शूराय नमः
ॐ दैत्यकुलान्तकाय नमः
ॐ सुरार्चिताय नमः
ॐ महातेजसे नमः (७०)
ॐ रामचूड़ामणि प्रदाय नमः
ॐ कामरूपिणे नमः
ॐ पिंगलाक्षाय नमः
ॐ वार्द्धिमैनाक पूजिताय नमः
ॐ कबळीकृत मार्ताण्ड मण्डलाय नमः
ॐ विजितेन्द्रियाय नमः
ॐ राम सुग्रीव सन्धात्रे नमः
ॐ महारावण मर्दनाय नमः
ॐ स्फटिकाभाय नमः
ॐ वागधीशाय नमः (८०)
ॐ नवव्याकृति पण्डिताय नमः
ॐ चतुर्बाहवे नमः
ॐ दीनबन्धवे नमः
ॐ महात्मने नमः
ॐ भक्तवत्सलाय नमः
ॐ संजीवन नगाहर्त्रे नमः
ॐ शुचये नमः
ॐ वाग्मिने नमः
ॐ दृढ़व्रताय नमः
ॐ कालनेमि प्रमथनाय नमः (९०)
ॐ हरि मर्कट मर्कटाय नमः
ॐ दान्ताय नमः
ॐ शान्ताय नमः
ॐ प्रसन्नात्मने नमः
ॐ दशकण्ठमदापहृते नमः
ॐ योगिने नमः
ॐ रामकथा लोलाय नमः

In Public domain. Digitization Muthulakshmi Research Academy

ॐ सीतान्वेषण पण्डिताय नमः
ॐ वज्रद्रंष्ट्राय नमः
ॐ वज्रनखाय नमः (१००)
ॐ रुद्रवीर्य समुद्भवाय नमः
ॐ इन्द्रजित् प्रहितामोघ ब्रह्मास्त्र विनिवारकाय नमः
ॐ पार्थध्वजाग्र संवासिने नमः
ॐ शरपञ्जर भेदकाय नमः
ॐ दशबाहवे नमः
ॐ लोकपूज्याय नमः
ॐ जाम्बवत्प्रीतिवर्धनाय नमः
ॐ सीतासमेत श्रीराम पाद सेवा धुरन्धराय नमः (१०८)

॥ श्री नवग्रह अष्टोत्तरशतनामावळिः ॥

॥ सूर्य ॥

ॐ भानवे नमः
ॐ हंसाय नमः
ॐ भास्कराय नमः
ॐ सूर्याय नमः
ॐ शूराय नमः
ॐ तमोहराय नमः
ॐ रथिने नमः
ॐ विश्वधृते नमः
ॐ अव्याप्त्रे नमः
ॐ हरये नमः
ॐ वेदमयाय नमः
ॐ विभवे नमः

॥ चन्द्र ॥

ॐ शुद्धांशवे नमः
ॐ शुभ्रांशवे नमः
ॐ चन्द्राय नमः
ॐ अब्जनेत्र समुद्भवाय नमः
ॐ ताराधिपाय नमः
ॐ रोहिणीशाय नमः
ॐ शम्भुमूर्ति कृतालयाय नमः
ॐ औषधीड्याय नमः
ॐ ओषधिपतये नमः
ॐ ईश्वरधराय नमः
ॐ सुधानिधये नमः
ॐ सकलाह्लादनकराय नमः

॥ अंगारक ॥

ॐ भौमाय नमः
ॐ भूमिसुताय नमः
ॐ भूतमान्याय नमः
ॐ समुद्भवाय नमः
ॐ आर्याय नमः
ॐ अग्निकृते नमः
ॐ रोहितांगाय नमः

In Public domain. Digitization Muthulakshmi Research Academy

ॐ रक्तवस्त्र धराय नमः
ॐ शुचये नमः
ॐ मंगळाय नमः
ॐ अंगारकाय नमः
ॐ रक्तमालिने नमः

॥ बुध ॥

ॐ मायाविशारदाय नमः
ॐ बुधाय नमः
ॐ तारासुताय नमः
ॐ सौम्याय नमः
ॐ रोहिणी गर्भ संभूताय नमः
ॐ चन्द्रात्मजाय नमः
ॐ सोमवंशकराय नमः
ॐ श्रुति विशारदाय नमः
ॐ सत्यसन्धाय नमः
ॐ सत्य सिन्धवे नमः
ॐ विधुसुताय नमः
ॐ विबुधाय नमः

॥ गुरु ॥

ॐ विभवे नमः
ॐ वाक्कृते नमः
ॐ ब्राह्मणाय नमः
ॐ ब्रह्मणे नमः
ॐ धिषणाय नमः
ॐ शुभवेषधराय नमः
ॐ गीष्पतये नमः
ॐ गुरवे नमः
ॐ इन्द्रपुरोहिताय नमः
ॐ जीवाय नमः
ॐ निर्ज्जर पूजिताय नमः
ॐ पीताम्बरालंकृताय नमः

॥ शुक्र ॥

ॐ भृगवे नमः
ॐ भार्गव सम्भूताय नमः
ॐ निशाचर गुरवे नमः
ॐ कवये नमः
ॐ भृत्यखेदहराय नमः
ॐ भृगुसुताय नमः
ॐ वर्षकृते नमः
ॐ दीन राज्यदाय नमः
ॐ शुक्राय नमः
ॐ शुक्रस्वरूपाय नमः
ॐ राज्यदाय नमः
ॐ लयकृताय नमः

॥ शनैश्चर ॥

ॐ कोणाय नमः
ॐ शनैश्चराय नमः
ॐ मन्दाय नमः
ॐ छायाहृदयनन्दनाय नमः
ॐ मार्त्ताण्डजाय नमः
ॐ पंगवे नमः
ॐ भानुतनूभवाय नमः
ॐ यमानुजाय नमः
ॐ अतिभयकृते नमः

In Public domain. Digitization Muthulakshmi Research Academy

ॐ नीलाय नमः
ॐ सूर्यवंशजाय नमः
ॐ निर्मल देहाय नमः

॥ राहु॥

ॐ राहवे नमः
ॐ स्वर्भानवे नमः
ॐ आदित्यचन्द्रद्वेषिणे नमः
ॐ भुजंगमाय नमः
ॐ सिंहिकेशाय नमः
ॐ गुणवते नमः
ॐ रात्रिपति पीडिताय नमः
ॐ अहिराजे नमः
ॐ शिरोहीनाय नमः
ॐ विषधराय नमः
ॐ महाकायाय नमः
ॐ महाभूताय नमः

॥ केतु॥

ॐ ब्राह्मणाय नमः
ॐ ब्रह्मसंभूताय नमः
ॐ रविकृते नमः
ॐ राहुरूपधृते नमः
ॐ केतवे नमः
ॐ केतुस्वरूपाय नमः
ॐ खेचराय नमः
ॐ सुकृतालयाय नमः
ॐ ब्रह्मविदे नमः
ॐ ब्रह्मपुत्राय नमः
ॐ कुमारकाय नमः
ॐ ब्राह्मणप्रीताय नमः

॥ श्री सुब्रह्मण्याष्टोत्तरशतनामावळिः ॥

ॐ स्कन्दाय नमः
ॐ गुहाय नमः
ॐ षणमुखाय नमः
ॐ फालनेत्रसुताय नमः
ॐ प्रभवे नमः
ॐ पिंगलाय नमः
ॐ कृत्तिकासूनवे नमः
ॐ शिखिवाहनाय नमः
ॐ द्विषड्भुजाय नमः
ॐ द्विषण्णेत्राय नमः (१०)
ॐ शक्तिधराय नमः
ॐ पिशिताशप्रभंजनाय नमः
ॐ तारकासुरसंहारिणे नमः
ॐ रक्षोबलविमर्दनाय नमः
ॐ मत्ताय नमः
ॐ प्रमत्ताय नमः

In Public domain. Digitization Muthulakshmi Research Academy

ॐ उन्मत्ताय नमः
ॐ सुरसैन्यसुरक्षकाय नमः
ॐ देवसेनापतये नमः
ॐ प्राज्ञाय नमः (२०)
ॐ कृपालवे नमः
ॐ भक्तवत्सलाय नमः
ॐ उमासुताय नमः
ॐ शक्तिधराय नमः
ॐ कुमाराय नमः
ॐ क्रौञ्चदारणाय नमः
ॐ सेनान्ये नमः
ॐ अग्निजन्मने नमः
ॐ विशाखाय नमः
ॐ शंकरात्मजाय नमः (३०)
ॐ शिवस्वामिने नमः
ॐ गणस्वामिने नमः
ॐ सनातनाय नमः
ॐ सर्वस्वामिने नमः
ॐ अनन्तशक्तये नमः
ॐ अक्षोभ्याय नमः
ॐ पार्वतीप्रियनन्दनाय नमः
ॐ गङ्गासुताय नमः
ॐ शरोद्भूताय नमः
ॐ आहूताय नमः (४०)
ॐ पावकात्मजाय नमः
ॐ जृम्भाय नमः
ॐ प्रजृम्भाय नमः
ॐ उज्जृम्भाय नमः
ॐ कमलासनसंस्तुताय नमः
ॐ एकवर्णाय नमः
ॐ द्विवर्णाय नमः
ॐ त्रिवर्णाय नमः
ॐ सुमनोहराय नमः
ॐ चतुर्वर्णाय नमः (५०)
ॐ पञ्चवर्णाय नमः
ॐ प्रजापतये नमः
ॐ अहस्पतये नमः
ॐ अग्निगर्भाय नमः
ॐ शमीगर्भाय नमः
ॐ विश्वरेतसे नमः
ॐ सुरारिघ्ने नमः
ॐ हरिद्वर्णाय नमः
ॐ शुभकाराय नमः
ॐ वटवे नमः (६०)
ॐ पटुवेषभृत नमः
ॐ पूष्णे नमः
ॐ गभस्तये नमः
ॐ गहनाय नमः

In Public domain. Digitization Muthulakshmi Research Academy

ॐ चन्द्रवर्णाय नमः
ॐ कलाधराय नमः
ॐ मायाधराय नमः
ॐ महामायिने नमः
ॐ कैवल्याय नमः
ॐ शंकरात्मजाय नमः (७०)
ॐ विश्वयोनये नमः
ॐ अमेयात्मने नमः
ॐ तेजोनिधये नमः
ॐ अनामयाय नमः
ॐ परमेष्ठिने नमः
ॐ परब्रह्मणे नमः
ॐ वेदगर्भाय नमः
ॐ विराट्सुताय नमः
ॐ पुलिन्दकन्याभर्त्रे नमः
ॐ महासारस्वतावृताय नमः (८०)
ॐ आश्रिताखिलदात्रे नमः
ॐ चोरघ्नाय नमः
ॐ रोगनाशनाय नमः
ॐ अनन्तमूर्तये नमः
ॐ आनन्दाय नमः
ॐ शिखण्डिने नमः
ॐ कृतकेतनाय नमः
ॐ डम्भाय नमः
ॐ परमडम्भाय नमः
ॐ महाडम्भाय नमः (९०)
ॐ वृषाकपये नमः
ॐ कारणोपात्तदेहाय नमः
ॐ कारणातीतविग्रहाय नमः
ॐ अनीश्वराय नमः
ॐ अमृताय नमः
ॐ प्राणाय नमः
ॐ प्राणायामपरायणाय नमः
ॐ विरुद्धहन्त्रे नमः
ॐ वीरघ्नाय नमः
ॐ रक्तश्याम-गलाय नमः (१००)
ॐ सुब्रह्मण्याय नमः
ॐ गुहाय नमः
ॐ प्रीताय नमः
ॐ ब्रह्मण्याय नमः
ॐ ब्राह्मणप्रियाय नमः
ॐ वंशवृद्धिकराय नमः
ॐ वेदवेद्याय नमः
ॐ अक्षयफलप्रदाय नमः (१०८)

॥ इति सुब्रह्मण्याष्टोत्तरशत-नामावळिः ॥

In Public domain. Digitization Muthulakshmi Research Academy

॥ श्री दुर्गा अष्टोत्तरशतनामावळिः ॥

॥ दुर्गा ध्यानम्॥

मातर्मे मधुकैटभघ्नि महिष प्राणाप हारोद्यमे
हेला निर्मित धूम्रलोचनवधे हे चण्डमुण्डार्दिनि।
निश्शेषीकृत रक्तबीज दनुजे नित्ये निशुंभा पहे
शुंभ ध्वंसिनि संहराति दुरितं दुर्गे नमस्तेऽम्बिके॥

ॐ देव्यै नमः
ॐ दुर्गायै नमः
ॐ त्रिभुवनेश्वर्वै नमः
ॐ यशोदागर्भ सम्भूतायै नमः
ॐ नारायणवरप्रियायै नमः
ॐ नन्दगोप कुलजातायै नमः
ॐ मंगल्यायै नमः
ॐ कुलवर्धिन्यै नमः
ॐ कंसविद्रावणकर्यै नमः
ॐ असुर क्षयंङ्कर्यै नमः (१०)
ॐ शिलातट विनिक्षिप्तायै नमः
ॐ आकाश गामिन्यै नमः
ॐ वासुदेवभगिन्यै नमः
ॐ दिव्यमाल्य विभूषितायै नमः
ॐ दिव्याम्बरधरायै नमः
ॐ खड्ग खेटक धारिण्यै नमः
ॐ शिवायै नमः
ॐ पापदारिण्यै नमः
ॐ वरदायै नमः
ॐ कृष्णायै नमः (२०)
ॐ कुमार्यै नमः
ॐ ब्रह्मचारिण्यै नमः
ॐ बालार्कसदृशाकारायै नमः
ॐ पूर्णचन्द्रनिभाननायै नमः
ॐ चतुर्भुजायै नमः
ॐ चतुर्वक्त्रायै नमः
ॐ पीनश्रोणिपयोधरायै नमः
ॐ मयूर पिच्छ वलयायै नमः
ॐ केयूरांगदधारिण्यै नमः
ॐ कृष्णाच्छविसमायै नमः (३०)
ॐ कृष्णायै नमः
ॐ संकर्षणसमाननायै नमः
ॐ इन्द्रध्वज समबाहुधारिण्यै नमः
ॐ पात्रधारिण्यै नमः
ॐ पङ्कजधारिण्यै नमः
ॐ घण्टाधारिण्यै नमः
ॐ धनुर्धारिण्यै नमः

In Public domain. Digitization Muthulakshmi Research Academy

ॐ महाचक्रधारिण्यै नमः
ॐ विविधायुधधरायै नमः
ॐ कुण्डलपूर्णकर्ण
विभूषितायै नमः (४०)
ॐ चन्द्रविस्फुरित मुख
विराजितायै नमः
ॐ मुकुटविराजितायै नमः
ॐ शिखिपिच्छध्वज
विराजितायै नमः
ॐ कौमार व्रत धरायै नमः
ॐ त्रिदिव पावयित्र्यै नमः
ॐ त्रिदश पूजितायै नमः
ॐ त्रैलोक्यरक्षिण्यै नमः
ॐ महिषासुर नाशिन्यै नमः
ॐ प्रसन्नायै नमः
ॐ सुर श्रेष्ठायै नमः (५०)
ॐ शिवायै नमः
ॐ जयायै नमः
ॐ विजयायै नमः
ॐ संग्रामजय प्रदायै नमः
ॐ वरदायै नमः
ॐ विन्ध्य वासिन्यै नमः
ॐ काळ्यै नमः
ॐ काल्यै नमः
ॐ महाकाळ्यै नमः

ॐ सुधाप्रियायै नमः (६०)
ॐ मांसप्रियायै नमः
ॐ पशुप्रियायै नमः
ॐ भूतानुसृतायै नमः
ॐ वरदायै नमः
ॐ कामचारिण्यै नमः
ॐ पापहरिण्यै नमः
ॐ कीर्त्यै नमः
ॐ श्रियै नमः
ॐ क्रियायै नमः
ॐ धृत्यै नमः (७०)
ॐ सिद्ध्यै नमः
ॐ ह्रियै नमः
ॐ विद्यायै नमः
ॐ सन्तत्यै नमः
ॐ मत्यै नमः
ॐ सन्ध्यायै नमः
ॐ रामायै नमः
ॐ प्रभायै नमः
ॐ निद्रायै नमः
ॐ ज्योत्स्नायै नमः (८०)
ॐ कान्त्यै नमः
ॐ क्षमायै नमः
ॐ दयायै नमः
ॐ बन्धननाशिन्यै नमः

In Public domain. Digitization Muthulakshmi Research Academy

ॐ मोहनाशिन्यै नमः
ॐ पुत्रापमृत्युनाशिन्यै नमः
ॐ धनक्षयनाशिन्यै नमः
ॐ व्याधि नाशिन्यै नमः
ॐ मृत्यु नाशिन्यै नमः
ॐ भयनाशिन्यै नमः (९०)
ॐ पद्मपत्राक्ष्यै नमः
ॐ दुर्गायै नमः
ॐ शरण्यायै नमः
ॐ भक्तवत्सलायै नमः
ॐ सौख्यदायै नमः
ॐ आरोग्यदायै नमः
ॐ राज्यदायै नमः
ॐ आयुर्दायै नमः
ॐ वपुर्द्दायै नमः
ॐ सुतदायै नमः (१००)
ॐ प्रवास रक्षिकायै नमः
ॐ नगर रक्षिकायै नमः
ॐ संग्राम रक्षिकायै नमः
ॐ शत्रुसङ्कट रक्षिकायै नमः
ॐ अटवीदुर्ग कान्तार रक्षिकायै नमः
ॐ सागर गिरि रक्षिकायै नमः
ॐ सर्वकार्य सिद्धि प्रदायिकायै नमः
ॐ दुर्गापरमेश्वर्यै नमः (१०८)

॥ श्री दक्षिणामूर्तिस्तोत्रम् ॥

गुरवे सर्वलोकानां भिषजे भवरोगिणाम्।
निधये सर्वविद्यानां दक्षिणामूर्तये नमः॥
ॐ नमः प्रणवार्थाय शुद्धज्ञानस्वरूपिणे।
निर्मलाय प्रशान्ताय दक्षिणामूर्तये नमः॥
वटविटपिसमीपे भूमि भागे निषण्णं
सकलमुनिजनानां ज्ञानदातारमारात्।
त्रिभुवनगुरुमीशं दक्षिणामूर्तिदेवं
जनन मरण दुःख च्छेद दक्षं नमामि॥

★★★

In Public domain. Digitization Muthulakshmi Research Academy

॥ श्री दक्षिणामूर्ति अष्टोत्तरशतनामावळिः ॥

ॐ ओंकार सिंहसर्वेन्द्राय नमः
ॐ ओंकारोद्यान कोकिलाय नमः
ॐ ओंकार नीडशुक राजे नमः
ॐ ओंकाराारण्य कुञ्जराय नमः
ॐ नगराज सुताजानये नमः
ॐ नगराज निजालयाय नमः
ॐ नवमाणिक्य मालाढ्याय नमः
ॐ नवतन्त्र शिखामणये नमः
ॐ नन्दिताशेष मौनीन्द्राय नमः
ॐ नन्दीशादिम देशिकाय नमः (१०)
ॐ मोहन वसुधासाराय नमः
ॐ मोहाम्बुज सुधाकराय नमः
ॐ मोहान्धकार तारणाय नमः
ॐ मोहोत्पल नभोमणये नमः
ॐ भक्तज्ञानाब्धि शीतांशवे नमः
ॐ भक्तज्ञान तृणानलाय नमः
ॐ भक्ताम्भोज सहस्रांशवे नमः
ॐ भक्तकेकि घनाघनाय नमः
ॐ भक्तकैरव राकेन्दवे नमः
ॐ भक्तकोक दिवाकराय नमः (२०)
ॐ गजाननादि संपूज्याय नमः
ॐ गजचर्मोज्ज्वलाकृतये नमः
ॐ गंगाधवळ दिव्यांगाय नमः
ॐ गंगा पङ्क लसज्जटाय नमः
ॐ गगनाम्बर संवीताय नमः
ॐ गगनामुक्त मूर्धजाय नमः
ॐ वदनाब्ज जिताब्जश्रियै नमः
ॐ वदनेन्दु स्फुरद्दिशाय नमः
ॐ वरदानैक निपुणाय नमः
ॐ वरवीणोज्ज्वलत्कराय नमः (३०)
ॐ वनवास समुल्लासाय नमः
ॐ वनवीरैक लोलुपाय नमः
ॐ तेजः पुञ्जघ नाकाराय नमः
ॐ तेजसामभिभासकाय नमः
ॐ विनेयानां तेजः प्रदाय नमः
ॐ तेजोमय निजाश्रयाय नमः
ॐ दमितानङ्ग संग्रामाय नमः
ॐ दरहास जितांगनाय नमः
ॐ दयारस सुधासिंधवे नमः
ॐ दरिद्र धनशेवधये नमः (४०)
ॐ क्षीरेन्दु स्फटिकाकाराय नमः
ॐ क्षीरेन्दु मुकुटोज्ज्वलाय नमः
ॐ क्षीरोपहार रसिकाय नमः
ॐ क्षिप्रैश्वर्य फल प्रदाय नमः
ॐ नानाभरण मुग्द्धांगाय नमः
ॐ नारी सम्मोहनाकृतये नमः

In Public domain. Digitization Muthulakshmi Research Academy

ॐ नाद ब्रह्म रसास्वादिने नमः
ॐ नाग भूषण भूषिताय नमः
ॐ मूर्ति निन्दित कन्दर्पाय नमः
ॐ मूर्तामूर्त जगद्वपुषे नमः (५०)
ॐ मूकाज्ञान तमोभानवे नमः
ॐ मूर्तिमत्कल्प पादपाय नमः
ॐ तरुणादित्य सङ्काशाय नमः
ॐ तन्त्री वादन तत्पराय नमः
ॐ तरुमूलैक निलयाय नमः
ॐ तप्तजाम्बू नदप्रभाय नमः
ॐ तत्वपुस्तोल्लसत्पाणये नमः
ॐ तपनोडुप लोचनाय नमः
ॐ यमसन्नुत सत्कीर्तये नमः
ॐ यमसंयम संयुताय नमः (६०)
ॐ यतिरूप धराय मौनिने नमः
ॐ यतीन्द्रोपास्य विग्रहाय नमः
ॐ मन्दारहार रुचिराय नमः
ॐ मदनायुत सुन्दराय नमः
ॐ मन्दस्मित लसद्वक्त्राय नमः
ॐ मधुराधर पल्लवाय नमः
ॐ मञ्जीर मञ्जु पादाब्जाय नमः
ॐ मणिपट्टोल्लसत्कटये नमः
ॐ हस्ताङ्कुरित चिन्मुद्राय नमः
ॐ हठयोग परमोत्तमाय नमः (७०)
ॐ हंसजप्याक्ष मालाढ्याय नमः
ॐ हंसेन्द्राराध्य पादुकाय नमः
ॐ मेरुश्रृंग तटोल्लसाय नमः
ॐ मेघ श्याम मनोहराय नमः
ॐ मेधांकुराल वालाग्र्याय नमः
ॐ मेधापक्व फलद्रुमाय नमः
ॐ धार्मिकान्तर्गुहावासाय नमः
ॐ धर्ममार्ग प्रवर्तकाय नमः
ॐ तापत्रय निजारामाय नमः
ॐ धर्मोत्तम मनोरथाय नमः (८०)
ॐ प्रबोधोत्कार दीपश्रिये नमः
ॐ प्रकाशित जगत्त्रयाय नमः
ॐ प्रज्ञाचन्द्र शिलाचन्द्राय नमः
ॐ प्रज्ञामणि वराकराय नमः
ॐ ज्ञानान्तरान्तर भासात्मने नमः
ॐ ज्ञातृज्ञाति विदूरकाय नमः
ॐ ज्ञाताज्ञाद्वैत दिव्यांगाय नमः
ॐ ज्ञातृज्ञाति कुलागताय नमः
ॐ प्रपन्न पारिजाताग्र्याय नमः
ॐ प्रणतार्त्यब्धि बाडवाय नमः (९०)
ॐ भूतानां प्रमाण भूताय नमः
ॐ प्रपञ्च वीतकारकाय नमः
ॐ यत्तत्वमसि संवेद्याय नमः
ॐ यक्षगेयात्म वैभवाय नमः
ॐ यज्ञादि देवतामूर्तये नमः
ॐ यजमान वपुर्धराय नमः

In Public domain. Digitization Muthulakshmi Research Academy

ॐ छत्राधिपति विश्वेशाय नमः
ॐ छत्रचामर सेविताय नमः
ॐ छन्दश्शास्त्रादि निपुणाय नमः
ॐ छलजात्यादि दूरकाय नमः (१००)
ॐ स्वाभाविक सुखैकात्मने नमः
ॐ स्वानुभूतिर सोदधये नमः
ॐ स्वाराज्य सम्पदद्ध्यक्षाय नमः
ॐ स्वात्माराम महामतये नमः
ॐ हाटकाभ जटाजूटाय नमः
ॐ हासोदस्तारि मण्डलाय नमः
ॐ हालाहलोज्ज्वल गळाय नमः
ॐ हारायुध मनोहराय नमः (१०८)
ॐ श्री दक्षिणामूर्तये नमः ॥

॥ श्री नन्दिकेश्वर अष्टोत्तर शतनामावाळिः ॥

॥ ध्यानम् ॥

विभ्राणं परशुं मृगं करतलै रीश प्रणामाञ्जलिं,
भस्मो द्धूळन पाण्डरं शशिकला गंगा कपर्दोज्वलम्।
पर्याय त्रिपुरान्तकं प्रमथप श्रेष्ठं गणं दैवतं,
ब्रह्मेन्द्राच्युत पूजितांघ्रि कमलं श्री नन्दिकेशं भजे॥

नन्दिकेश महाभाग शिव ध्यान परायण।
देव देवस्य सेवार्थ मनुज्ञां दातुमर्हसि॥

ओं नन्दिकेश्वराय नमः।
ओं ब्रह्मरूपिणे नमः।
ओं शिवध्यान परायणाय नमः।
ओं तीक्ष्ण श्रृंगाय नमः।
ओं वेद पादाय नमः।
ओं विरूपाय नमः।
ओं वृषभाय नमः।
ओं तुङ्ग शैलाय नमः।
ओं देव देवाय नमः।
ओं शिव प्रियाय नमः।१०।
ओं विराजमानाय नमः।
ओं नटनाय नमः।
ओं अग्निरूपाय नमः।
ओं धन प्रियाय नमः।
ओं सित चामर धारिणे नमः।
ओं वेदांगाय नमः।

In Public domain. Digitization Muthulakshmi Research Academy

ओं कनक प्रियाय नमः।
ओं कैलास वासिने नमः।
ओं देवाय नमः।
ओं स्थित पादाय नमः।२०।
ओं श्रुति प्रियाय नमः।
ओं श्वेतोपवीतिने नमः।
ओं नाट्य नन्दकाय नमः।
ओं किंकिणी धराय नमः।
ओं मत्त शृंगिणे नमः।
ओं हाट केशाय नमः।
ओं हेम भूषणाय नमः।
ओं विष्णु रूपिण्याय नमः।
ओं पृथ्वी रूपिणे नमः।
ओं निधीशाय नमः।३०।
ओं शिव वाहनाय नमः।
ओं गुळ प्रियाय नमः।
ओं चारुहासाय नमः।
ओं शृंगिणे नमः।
ओं नव तृण प्रियाय नमः।
ओं वेद साराय नमः।
ओं मन्त्र साराय नमः।
ओं प्रत्यक्षाय नमः।
ओं करुणा कराय नमः।
ओं शीघ्राय नमः।४०।
ओं ललाम कलिकाय नमः।
ओं शिव योगिने नमः।
ओं जलाधिपाय नमः।
ओं चारु रूपाय नमः।
ओं वृषेशाय नमः।
ओं सोम सूर्याग्नि लोचनाय नमः।
ओं सुन्दराय नमः।
ओं सोम भूषाय नमः।
ओं सुवक्त्राय नमः।
ओं कलि नाशनाय नमः।५०।
ओं सुप्रकाशाय नमः।
ओं महावीर्याय नमः।
ओं हंसाय नमः।
ओं अग्नि मयाय नमः।
ओं प्रभवे नमः।
ओं वरदाय नमः।
ओं रुद्र रूपाय नमः।
ओं मधुराय नमः।
ओं कामिक प्रियाय नमः।
ओं विशिष्टाय नमः।६०।
ओं दिव्य रूपाय नमः।
ओं उज्ज्वलिने नमः।

In Public domain. Digitization Muthulakshmi Research Academy

ओं ज्वाला नेत्राय नमः।
ओं संवर्ताय नमः।
ओं कालाय नमः।
ओं केशवाय नमः।
ओं सर्व दैवताय नमः।
ओं श्वेत वर्णाय नमः।
ओं शिवासीनाय नमः।
ओं चिन्मयाय नमः।७०।
ओं श्रृंग पट्टाय नमः।
ओं श्वेत चामर भूषाय नमः।
ओं देव राजाय नमः।
ओं प्रभा नन्दिने नमः।
ओं पण्डिताय नमः।
ओं परमेश्वराय नमः।
ओं नीरूपाय नमः।
ओं निराकाराय नमः।
ओं छिन्न दैत्याय नमः।
ओं नासा सूत्रिणे नमः। ८०।
ओं अनन्तेशाय नमः।
ओं तिल तण्डुल भक्षणाय नमः।
ओं वीर नन्दिने नमः।
ओं सरसाय नमः।
ओं विमलाय नमः।
ओं पट्ट सूत्राय नमः।
ओं काळ कण्ठाय नमः।
ओं शैलादिने नमः।
ओं शिलादन सुनन्दनाय नमः।
ओं कारणाय नमः।९०।
ओं श्रुति भक्ताय नमः।
ओं वीर घण्टा धराय नमः।
ओं धन्याय नमः।
ओं विष्णु नन्दिने नमः।
ओं शिव ज्वाला ग्राहिणे नमः।
ओं भद्राय नमः।
ओं अनघाय नमः।
ओं वीराय नमः।
ओं ध्रुवाय नमः।
ओं धात्रे नमः।१००।
ओं शाश्वताय नमः।
ओं प्रदोष प्रिय रूपिणे नमः।
ओं वृषाय नमः।
ओं कुण्डल धृते नमः।
ओं भीमाय नमः।
ओं सितवर्ण स्वरूपिणे नमः।
ओं सर्वात्मने नमः।
ओं शर्व विख्याताय नमः।१०८।

★★★

In Public domain. Digitization Muthulakshmi Research Academy

॥ श्री लिंगाष्टोत्तर शतनामावळिः ॥

॥ ध्यानम् ॥

लिंगमूर्तिं शिवं स्तुत्वा गायत्र्या योगमाप्तवान्।
निर्वाणं परमं ब्रह्म वसिष्ठोन्यश्च शंकरात्॥

ॐ लिंग मूर्तये नमः।
ॐ शिवलिंगाय नमः।
ॐ अद्भुत लिंगाय नमः।
ॐ अनुगत लिंगाय नमः।
ॐ अव्यक्त लिंगाय नमः।
ॐ अर्थ लिंगाय नमः।
ॐ अच्युत लिंगाय नमः।
ॐ अनन्त लिंगाय नमः।
ॐ अमृत लिंगाय नमः।
ॐ अनेक लिंगाय नमः।१०।
ॐ अनेक स्वरूप लिंगाय नमः।
ॐ अनादि लिंगाय नमः।
ॐ आदि लिंगाय नमः।
ॐ आनन्द लिंगाय नमः।
ॐ आत्मानन्द लिंगाय नमः।
ॐ आर्जित पापविनाश-लिंगाय नमः।
ॐ आश्रित रक्षक लिंगाय नमः।
ॐ इन्दु लिंगाय नमः।
ॐ इन्द्रिय लिंगाय नमः।
ॐ इन्द्रादि प्रिय लिंगाय नमः।२०।
ॐ ईश्वर लिंगाय नमः।
ॐ ऊर्जित लिंगाय नमः।
ॐ ऋग्वेद श्रुति लिंगाय नमः।
ॐ एक लिंगाय नमः।
ॐ ऐश्वर्य लिंगाय नमः।
ॐ ओंकार लिंगाय नमः।
ॐ ह्रींकार लिंगाय नमः।
ॐ कनक लिंगाय नमः।
ॐ वेद लिंगाय नमः।
ॐ परम लिंगाय नमः।३०।
ॐ व्योम लिंगाय नमः।
ॐ सहस्त्र लिंगाय नमः।
ॐ वह्नि लिंगाय नमः।
ॐ पुराण लिंगाय नमः।

In Public domain. Digitization Muthulakshmi Research Academy

ॐ श्रुति लिंगाय नमः।
ॐ पाताळ लिंगाय नमः।
ॐ ब्रह्म लिंगाय नमः।
ॐ रहस्य लिंगाय नमः।
ॐ सप्त द्वीपोर्ध्व लिंगाय नमः।
ॐ नाग लिंगाय नमः।४०।
ॐ तेजो लिंगाय नमः।
ॐ ऊर्ध्व लिंगाय नमः।
ॐ अथर्व लिंगाय नमः।
ॐ साम लिंगाय नमः।
ॐ यज्ञाङ्ग लिंगाय नमः।
ॐ यज्ञ लिंगाय नमः।
ॐ तत्व लिंगाय नमः।
ॐ देव लिंगाय नमः।
ॐ विग्रह लिंगाय नमः।
ॐ रावण लिंगाय नमः।५०।
ॐ भ्राजो लिंगाय नमः।
ॐ सत्व लिंगाय नमः।
ॐ स्वर्ण लिंगाय नमः।
ॐ स्फटिक लिंगाय नमः।
ॐ भव लिंगाय नमः।
ॐ निस्त्रैगुण्य लिंगाय नमः।

ॐ मन्त्र लिंगाय नमः।
ॐ पुरुष लिंगाय नमः।
ॐ सर्वात्म लिंगाय नमः।
ॐ सर्वलोकाङ्ग लिंगाय नमः।६०।
ॐ बुद्धि लिंगाय नमः।
ॐ अहंकार लिंगाय नमः।
ॐ भूत लिंगाय नमः।
ॐ महेश्वर लिंगाय नमः।
ॐ सुन्दर लिंगाय नमः।
ॐ असुरेश्वर लिंगाय नमः।
ॐ सुरेश लिंगाय नमः।
ॐ महेश लिंगाय नमः।
ॐ शंकर लिंगाय नमः।
ॐ दानव नाश लिंगाय नमः।७०।
ॐ रवि चन्द्र लिंगाय नमः।
ॐ रूप लिंगाय नमः।
ॐ प्रपञ्च लिंगाय नमः।
ॐ विलक्षण लिंगाय नमः।
ॐ ताप निवारण लिंगाय नमः।
ॐ स्वरूप लिंगाय नमः।
ॐ सर्व लिंगाय नमः।
ॐ प्रिय लिंगाय नमः।

In Public domain. Digitization Muthulakshmi Research Academy

ॐ राम लिंगाय नमः।

ॐ मूर्त्ति लिंगाय नमः।८०।

ॐ महेश लिंगाय नमः।

ॐ वेदान्त लिंगाय नमः।

ॐ विश्वेश्वर लिंगाय नमः।

ॐ योगि लिंगाय नमः।

ॐ हृदय लिंगाय नमः।

ॐ चिन्मय लिंगाय नमः।

ॐ चिद्घन लिंगाय नमः।

ॐ महेश लिंगाय नमः।

ॐ लंकापुर लिंगाय नमः।

ॐ लालित लिंगाय नमः।९०।

ॐ चिदंबर लिंगाय नमः।

ॐ नारद सेवित लिंगाय नमः।

ॐ कमल लिंगाय नमः।

ॐ कैलास लिंगाय नमः।

ॐ करुणा रस लिंगाय नमः।

ॐ शान्त लिंगाय नमः।

ॐ गिरि लिंगाय नमः।

ॐ वल्लभ लिंगाय नमः।

ॐ शंकर लिंगाय नमः।

ॐ सर्वजन पूजित लिंगाय नमः।१००।

ॐ सर्वपातक नाशन लिंगाय नमः।

ॐ गौरी लिंगाय नमः।

ॐ वेद स्वरूप लिंगाय नमः।

ॐ सकल जन प्रिय लिंगाय नमः।

ॐ सकल जगद् रक्षक लिंगाय नमः।

ॐ इष्ट काम्यार्थ फल सिद्धि लिंगाय नमः।

ॐ शोभित लिंगाय नमः।

ॐ मंगळ लिंगाय नमः।१०८।

In Public domain. Digitization Muthulakshmi Research Academy

॥ श्री परमेश्वर-श्री ललिता अष्टोत्तरशतनाम स्तोत्रम् ॥

ॐ हिम भूधर शृंगाग्र विहाराय नमो नमः।
ॐ रजता चल शृंगाग्र मध्यस्थायै नमो नमः।
ॐ कैलासायित वृद्धोक्ष ककुत्स्थाय नमो नमः।
ॐ हिमाचल महावंश पावनायै नमो नमः।
ॐ कान्तार्ध भाग सौन्दर्य शरीराय नमो नमः।
ॐ शंकरार्धांग सौन्दर्य शरीरायै नमो नमः।
ॐ शरज्जीमूत संकाश विग्रहाय नमो नमः।
ॐ लसन्मरकत स्वच्छ विग्रहायै नमो नमः।
ॐ वाग्देवी वचनातीत सुन्दराय नमो नमः।
ॐ महातिशय सर्वाङ्ग लावण्यायै नमो नमः।
ॐ श्रीनाथ सोदरी रम्य नर्तकाय नमो नमः।
ॐ शशांक शेखर प्राण वल्लभायै नमो नमः।
ॐ सर्वदा शक्ति संयुक्त स्वरूपाय नमो नमः।
ॐ सदा पंचदशाब्दैक स्वरूपायै नमो नमः।
ॐ फणीन्द्रमणि सन्दीप्त सुजटाय नमो नमः।
ॐ वज्र माणिक्य कटक किरीटिन्यै नमो नमः।
ॐ चिता भस्मर जोद्भासि ललाटाय नमो नमः।
ॐ कस्तूरी तिलकोद्भासि निटिलायै नमो नमः।
ॐ पुण्य मन्दाकिनी युक्त कपर्दाय नमो नमः।
ॐ भस्म रेखांकित लसन्मस्तकायै नमो नमः।१०।
ॐ संपूर्ण सोम सूर्याग्नि लोचनाय नमो नमः।
ॐ विक चांभोरुह दळ लोचनायै नमो नमः।
ॐ फुल्ल चांपेय संकाश नासिकाय नमो नमः।
ॐ शरच्चांपेय पुष्पाभ नासिकायै नमो नमः।

In Public domain. Digitization Muthulakshmi Research Academy

ॐ रत्न स्फुरन्मणीन्द्रादि कुण्डलाय नमो नमः।

ॐ चलत्कांचन ताटंग युगळायै नमो नमः।

ॐ हिमाद्रिजा परामृष्ट कपोलाय नमो नमः।

ॐ मणि दर्पण संकाश कपोलायै नमो नमः।

ॐ मनोहर मृदु स्मेर वदनाय नमो नमः।

ॐ तांबूल पूरित स्मेर वदनायै नमो नमः।

ॐ लसन्मुक्तावळी तुल्य रदनाय नमो नमः।

ॐ सुपक्व दाड़िमी बीज रदनायै नमो नमः।

ॐ नील हालाहलोद्भासि कन्धराय नमो नमः।

ॐ कम्बु पूग समच्छाय कन्धरायै नमो नमः।

ॐ अशोक बिल्व रुद्राक्ष सुहाराय नमो नमः।

ॐ स्थूल मुक्ता फलोदार सुहारायै नमो नमः।

ॐ नागेन्द्र हार विलसद् श्रीकण्ठाय नमो नमः।

ॐ गिरीश बद्ध मांगल्य मंगळायै नमो नमः।

ॐ धृत ढक्का कपालेन्दु त्रिशूलाय नमो नमः।

ॐ पद्म पाशांकुश लसत् कराब्जायै नमो नमः।२०।

ॐ कुन्द मन्दार पुष्पौघ पूजिताय नमो नमः।

ॐ पद्म कैरव मन्दार सुमालिन्यै नमो नमः।

ॐ चन्दनागरु कस्तूरी लेपनाय नमो नमः।

ॐ सुवर्ण कुंभ युग्माभ सुकुचायै नमो नमः।

ॐ पन्नगज्या समा सक्त पिनाकाय नमो नमः।

ॐ रमणीय चतुर्बाहु संयुक्तायै नमो नमः।

ॐ चलद् भुजंग रुद्राक्ष केयूराय नमो नमः।

ॐ कनकांगद केयूर भूषितायै नमो नमः।

In Public domain. Digitization Muthulakshmi Research Academy

ॐ व्याघ्र चर्मांबरकृत वेषाढ्याय नमो नमः।
ॐ विद्युत् सन्निभ सौन्दर्य वसनायै नमो नमः।
ॐ अमृताब्धि सुतानाथ सायकाय नमो नमः।
ॐ बृहन्नितब विलस द्रशनायै नमो नमः।
ॐ उमा हृदय सर्वस्व तस्कराय नमो नमः।
ॐ सौभाग्य ज्ञात शृंगार मध्यगायै नमो नमः।
ॐ तारागण समावीत विग्रहाय नमो नमः।
ॐ दिव्य भूषण सन्दोह रञ्जितायै नमो नमः।
ॐ कल्पद्रुम गुणातीत पादाब्जाय नमो नमः।
ॐ पारिजात गुणाधिक्य पादाब्जायै नमो नमः।
ॐ नटनाकुंचित श्रीमच्छरणाय नमो नमः।
ॐ सुपद्मराग संकाश चरणायै नमो नमः।३०।
ॐ नन्दीश्वर महा स्कन्ध पीठस्थाय नमो नमः।
ॐ कामकोटि महा भद्र पीठस्थायै नमो नमः।
ॐ गौरी हृदय हर्षाब्धि पूर्णदाय नमो नमः।
ॐ श्रीकण्ठ नेत्र कुमुद चन्द्रिकायै नमो नमः।
ॐ क्षीराब्धि तनया नाथ रमणाय नमो नमः।
ॐ सचामर रमावाणी वीजितायै नमो नमः।
ॐ संसारार्णव मग्नानां वराहाय नमो नमः।
ॐ भक्त रक्षण दाक्षिण्य कटाक्षायै नमो नमः।
ॐ शैल राज सुताश्लेष सुखज्ञाय नमो नमः।
ॐ भूतेशा लिंगनोद्भूत पुळ्काङ्ग्यै नमो नमः।
ॐ सितासित समानार्ध स्वरूपाय नमो नमः।
ॐ अनंग जनकापांग वीक्षणायै नमो नमः।

In Public domain. Digitization Muthulakshmi Research Academy

ॐ नारसिंह महाकोप शामकाय नमो नमः।
ॐ ब्रह्मोपेन्द्र शिरोरत्न रंजितायै नमो नमः।
ॐ प्रमथादि महाभूत मण्डलाय नमो नमः।
ॐ शची मुखामर वधू सेवितायै नमो नमः।
ॐ लीला ताण्डव संमोद निर्भराय नमो नमः।
ॐ लीला कल्पित विध्यण्ड मण्डलायै नमो नमः।
ॐ एकादश महारुद्र सं सेव्याय नमो नमः।
ॐ अमृतादि महाशक्ति संवृतायै नमो नमः।४०।
ॐ सर्व सौभाग्य साम्राज्य दायकाय नमो नमः।
ॐ एकात पत्र साम्राज्य दायिकायै नमो नमः।
ॐ बाण रावण चण्डेश वरदाय नमो नमः।
ॐ सनकादि समाराध्य पादुकायै नमो नमः।
ॐ इन्द्रोपेन्द्र मुनीन्द्रादि वन्दिताय नमो नमः।
ॐ देवर्षि संस्तूयमान वैभवायै नमो नमः।
ॐ रघुपुंगव शोकाग्नि शामकाय नमो नमः।
ॐ कलशोद्भव दुर्वासः पूजितायै नमो नमः।
ॐ गणेशदेव सैन्येश वत्सलाय नमो नमः।
ॐ मत्तेभ वक्त्र षड्वक्त्र वत्सलायै नमो नमः।
ॐ ब्रह्म विष्णु प्रमाणाति विग्रहाय नमो नमः।
ॐ चक्रराज महायन्त्र मध्यवर्त्यै नमो नमः।
ॐ आद्यन्त हीनतेजौघ मनोज्ञाय नमो नमः।
ॐ चिदग्नि कुण्ड संभूत सुदेहायै नमो नमः।
ॐ बालेन्दु खण्ड विलसन्मुकुटाय नमो नमः।
ॐ शशांक खण्ड संयुक्त मुकुटायै नमो नमः।

In Public domain. Digitization Muthulakshmi Research Academy

ॐ चारु गौरी मनोरम्य सुनृत्ताय नमो नमः।

ॐ मत्त हंस वधू मन्द गमनायै नमो नमः।

ॐ योगिहृत् संशयोच्छेद कुठाराय नमो नमः।

ॐ वन्दारु जन सन्दोह वन्दितायै नमो नमः।५०।

ॐ सदा सुभिक्ष संपत्ति दायकाय नमो नमः।

ॐ अन्तर्मुख जनानन्द फलदायै नमो नमः।

ॐ अपांसुलांगना भीष्ट वरदाय नमो नमः।

ॐ पतिव्रतांगना भीष्ट फलदायै नमो नमः।

ॐ आश्चर्य करुणा पूर्ण सागराय नमो नमः।

ॐ अव्याज करुणापूर पूरितायै नमो नमः।

ॐ योगानन्द सदानन्द रंजिताय नमो नमः।

ॐ निरंजन चिदानन्द संयुक्तायै नमो नमः।

ॐ कोटि प्रचण्ड मार्ताण्ड प्रकाशाय नमो नमः।

ॐ सहस्त्र सूर्येन्द्वयुत प्रकाशायै नमो नमः।

ॐ चिन्तामणि महाद्वीप विहाराय नमो नमः।

ॐ रत्न चिन्तामणि गृह मध्यस्थायै नमो नमः।

ॐ विरिंचि पद्मनाभादि पूर्वजाय नमो नमः।

ॐ हानि वृद्धि गुणाधिक्य रहितायै नमो नमः।

ॐ हेम कूट मणिद्वीप लालसाय नमो नमः।

ॐ महा पद्माटवी मध्य निवासायै नमो नमः।

ॐ मनो वागादिकरण प्रेरकाय नमो नमः।

ॐ जाग्रत् स्वप्न सुषुप्तीनां साक्षि भूत्यै नमो नमः।

ॐ कैवल्याश्रय पादाब्ज युगळाय नमो नमः।

ॐ महा तापौघ पापानां विनाशिन्यै नमो नमः।६०।

In Public domain. Digitization Muthulakshmi Research Academy

ॐ तापत्रय महाभीति भंजनाय नमो नमः।
ॐ दुष्ट भीति महाभीति भंजनायै नमो नमः।
ॐ समस्त देव दनुज रक्षकाय नमो नमः।
ॐ समस्त देव दनुज प्रेरकायै नमो नमः।
ॐ अंगुष्ठ मात्र पुरुष स्वरूपाय नमो नमः।
ॐ समस्त हृदयांभोज निलयायै नमो नमः।
ॐ अंबिका हृदयां भोज निलयाय नमो नमः।
ॐ अनाहत महापद्म मंदिरायै नमो नमः।
ॐ कात्यायनी कंज नेत्र भास्कराय नमो नमः।
ॐ सहस्त्रार सरोजात वासितायै नमो नमः।
ॐ अक्षय्य मोक्ष साम्राज्य दायकाय नमो नमः।
ॐ पुनरावृत्ति रहित पुरस्थायै नमो नमः।
ॐ यक्ष किन्नर गन्धर्व सेविताय नमो नमः।
ॐ वाणी गायत्री सावित्री सन्नुतायै नमो नमः।
ॐ जंभारि विष्णु वागीश सन्नुताय नमो नमः।
ॐ नीला रमा भू संपूज्य पदाब्जायै नमो नमः।
ॐ कुंभ संभव संसेव्य चरणाय नमो नमः।
ॐ लोपामुद्रार्चित श्रीमच्चरणायै नमो नमः।
ॐ कोटि कन्दर्प सौन्दर्य शरीराय नमो नमः।
ॐ सहस्त्र रति सौन्दर्य शरीरायै नमो नमः।७०।
ॐ आर्त भक्त परित्राण संलक्ष्याय नमो नमः।
ॐ भावना मात्र संतुष्ट हृदयायै नमो नमः।
ॐ भक्त प्रार्थित सर्वार्थ कल्पकाय नमो नमः।
ॐ नत संपूर्ण विज्ञान सिद्धिदायै नमो नमः।

In Public domain. Digitization Muthulakshmi Research Academy

ॐ उपेन्द्र सोदरी प्राणवल्लभाय नमो नमः।

ॐ त्रिलोचन कृतोल्लास फलदायै नमो नमः।

ॐ दिव्यदेह प्रभादीप्त कैलासाय नमो नमः।

ॐ श्री सुधाब्धि मणिद्वीप मध्यगायै नमो नमः।

ॐ दक्ष प्रजापति मख ध्वंसकाय नमो नमः।

ॐ दक्षाध्वर विनिर्भेद साधनायै नमो नमः।

ॐ भस्मासुर प्राणहारि वल्लभाय नमो नमः।

ॐ श्री नाथ सोदरी भूमि शोभितायै नमो नमः।

ॐ शरणागत भक्तार्ति भेषजाय नमो नमः।

ॐ चन्द्र शेखर भक्तार्ति भंजनायै नमो नमः।

ॐ कालातीत गुणातीत स्वरूपाय नमो नमः।

ॐ सर्वोपाधि विनिर्मुक्त चैतन्यायै नमो नमः।

ॐ पाद युग्म स्मरत् प्राणि शरणाय नमो नमः।

ॐ नाम पारायणा भीष्ट फलदायै नमो नमः।

ॐ सर्ग संस्थिति संहार कारणाय नमो नमः।

ॐ सृष्टि स्थिति तिरोधान संकल्पायै नमो नमः।८०।

ॐ दिव्य पंचाक्षरी मन्त्र स्वरूपाय नमो नमः।

ॐ श्री षोडशाक्षरी मन्त्र मध्यगायै नमो नमः।

ॐ समस्त विषयातीत वैभवाय नमो नमः।

ॐ अनाद्यन्त स्वयं भूत दिव्य मूर्त्यै नमो नमः।

ॐ अनश्वर महाभाग्य भूतिदाय नमो नमः।

ॐ भक्त हंसवती मुख्य नियोगायै नमो नमः।

ॐ देव दानव दैत्येन्द्र संस्तुताय नमो नमः।

ॐ मातृ मण्डल संयुक्त ललितायै नमो नमः।

In Public domain. Digitization Muthulakshmi Research Academy

ॐ अंधकासुर संहार पण्डिताय नमो नमः।

ॐ भण्ड दैत्य महासद्म नाशनायै नमो नमः।

ॐ दशग्रीव महादर्प ध्वंसकाय नमो नमः।

ॐ क्रूर भण्ड शिरच्छेद निपुणायै नमो नमः।

ॐ विषाग्निदग्ध देवादि रक्षकाय नमो नमः।

ॐ धात्रच्युत सुराधीश सुखदायै नमो नमः।

ॐ त्रिपुरासुर संहार कोविदाय नमो नमः।

ॐ चण्ड मुण्ड निशुंभादि खण्डनायै नमो नमः।

ॐ फाल नेत्राग्नि संदग्ध कन्दर्पाय नमो नमः।

ॐ रक्ताक्ष रक्त जिह्वादि शिक्षणायै नमो नमः।

ॐ मृकण्डुतनय प्राण रक्षकाय नमो नमः।

ॐ महिषासुरदो वीर्य निग्रहायै नमो नमः।९०।

ॐ गिरि राज सुता सौख्य वर्धकाय नमो नमः।

ॐ अभ्रकेश महोत्साह करणायै नमो नमः।

ॐ वामांग विलसद् गौरी वीक्षिताय नमो नमः।

ॐ महेश युक्त नटन तत्परायै नमो नमः।

ॐ पार्वती वदनां भोज भास्कराय नमो नमः।

ॐ निज भर्तृ मुखां भोज चिन्तनायै नमो नमः।

ॐ नन्दि मृदंग संराव मुदिताय नमो नमः।

ॐ वृषभ ध्वज विज्ञान तपस्सिद्ध्यै नमो नमः।

ॐ जन्म मृत्यु जरा चक्र नाशनाय नमो नमः।

ॐ जन्म मृत्यु जरा रोग भंजनायै नमो नमः।

ॐ सद्भक्ति मुक्ति संपत्ति दायकाय नमो नमः।

ॐ विरक्ति भक्ति विज्ञान सिद्धिदायै नमो नमः।

In Public domain. Digitization Muthulakshmi Research Academy

ॐ आशा द्वेष समुद्भूत क्लेशघ्नाय नमो नमः।
ॐ काम क्रोधादि षड्वर्ग नाशनायै नमो नमः।
ॐ योगिहृत् पुण्डरीकाक्ष प्रकाशाय नमो नमः।
ॐ राज राजार्चित पद सरोजायै नमो नमः।
ॐ वेद वेदांग शास्त्रार्थ बोधकाय नमो नमः।
ॐ सर्व वेदान्त सिद्धान्त सुतत्वायै नमो नमः।
ॐ ढक्का नादोद्भवच्छब्द सूत्रधात्रे नमो नमः।
ॐ श्री वीर भक्त विज्ञान निदानायै नमो नमः।१००।
ॐ समस्त लोक संहार पण्डिताय नमो नमः।
ॐ अशेष दुष्ट दनुज सूदनायै नमो नमः।
ॐ पार्वती हृदया राम सुपुष्पाय नमो नमः।
ॐ साक्षाच्छ्री दक्षिणामूर्ति मनोज्ञायै नमो नमः।
ॐ सर्वक्रतु फल प्राप्ति कारणाय नमो नमः।
ॐ हय मेधाग्र संपूज्य महिमायै नमो नमः।
ॐ दक्ष प्रजापति सुता प्राणेशाय नमो नमः।
ॐ दक्ष प्रजापति सुता वेषाढ्यायै नमो नमः।
ॐ महा पाशुपतास्त्रादि भूषिताय नमो नमः।
ॐ सुम बाणेक्षु कोदण्ड मण्डितायै नमो नमः।
ॐ अद्रिजा तपसा कृष्ट मोहनाय नमो नमः।
ॐ नित्य यौवन मांगल्य मंगळायै नमो नमः।
ॐ साक्षात्शक्ति समायुक्त सुशक्ताय नमो नमः।
ॐ महादेव समायुक्त महादेव्यै नमो नमः।
ॐ सर्व स्वरूप सर्वेश सर्वज्ञाय नमो नमः।
ॐ चतुर्विंशति तत्वैक स्वरूपाये नमो नमः।१०८।

In Public domain. Digitization Muthulakshmi Research Academy

॥ धूप दीपादि उपचारः ॥

धूपं—धूरसि धूर्व धूर्वन्तं धूर्वतं योऽस्मान् धूर्वति तं धूर्वयं वयं धूर्वाम। त्वं देवानामसि सस्नितमं पप्रितमं जुष्टतमं वह्नितमं देवहूतमं मह्रुतमसि हविर्धानं धृ ँ हस्व माह्वा मित्रस्यत्वा चक्षुषा प्रेक्षे मा भेर्मासं विक्था मात्वा हि ँ सिषम्॥

धूपः—विज्यं धनुः कपर्दिनो विशल्यो बाणवा ँ उत। अनेशन्नस्येषव आभुरस्य निषंगथिः। ओं ह्रीं नमः शिवाय। बलाय नमः। धूपमाघ्रापयामि॥

दीपं—उद्दीप्यस्व जातवेदोऽपहन्निर्ऋतिं मम। पशूँश्च मह्य मावह जीवनञ्च दिशो दिश। मानो हि ँ सीज्जातवेदो गामश्वं पुरुषं जगत्। अभि भ्रदग्न आगहि श्रियामा परिपातय॥

दीपः—या ते हेतिर्मीढुष्टम हस्ते बभूव ते धनुः। तयाऽस्मान् विश्वतस्त्वमयक्ष्मया परिब्भुज। ओं ह्रीं नमः शिवाय। बलप्रमथनाय नमः। दीपं दर्शयामि॥ आचमनीयं समर्पयामि॥

नैवेद्यम्—ओं भूर्भुवस्सुवः। तत्सवितुर्वरेण्यं भर्गो देवस्य धीमहि। धियो यो नः प्रचोदयात्। देव सवितः प्रसुव। सत्यं त्वर्तेन परिषिञ्चामि।

अमृतोपस्तरणमसि। ओं प्राणाय स्वाहा। ओं अपानाय स्वाहा। ओं व्यानाय स्वाहा। ओं उदानाय स्वाहा। ओं समानाय स्वाहा। ओं ब्रह्मणे स्वाहा॥ नमस्ते अस्त्वायु धायानातताय धृष्णवे। उभाभ्या मुत ते नमो बाहुभ्यां तव धन्वने॥ ओं ह्रीं नमः शिवाय। सर्वभूतदमनाय नमः॥ महानैवेद्यं निवेदयामि॥ मध्ये मध्ये अमृतपानीयं समर्पयामि। अमृतापिधानमसि। हस्त प्रक्षालनं समर्पयामि। पादप्रक्षालनं समर्पयामि। आचमनीयं समर्पयामि॥

In Public domain. Digitization Muthulakshmi Research Academy

कर्पूर तांबूलं—परि ते धन्वनो हेतिरस्मान् वृणक्तु विश्वतः। अथो य इषुधिस्तवारे अस्मन्निधेहि तम्। ओं ह्रीं नमः शिवाय। मनोन्मनाय नमः। कर्पूर तांबूलं समर्पयामि॥

नीराजनं—सोमो वा एतस्य राज्यमादत्ते। यो राजासन् राज्योवा सोमेन् यजते। देवसुवा मेतानि हवी ॅं षि भवन्ति। एतावन्तो वै देवाना ॅं सवाः। त एवास्मै सवा न्प्रयच्छन्ति। त एनं पुनस्सुवन्ते राज्याय। देवसू राजा भवति॥

नीराजनम्—नमस्ते अस्तु भगवन् विश्वेश्वराय महादेवाय त्र्यम्बकाय त्रिपुरान्तकाय त्रिकाग्निकालाय कालाग्निरुद्राय नीलकण्ठाय मृत्युं जयाय सर्वेश्वराय सदाशिवाय श्रीमन्महादेवाय नमः॥ कर्पूरनीराजनदीपं दर्शयामि॥

रक्षाधारणम्—बृहत्साम क्षत्रभृद् वृद्धवृष्णियम्। त्रिष्टुभौजश्शुभित मुग्रवीरम्। इन्द्रस्तोमेन पंचदशेन। मध्यमिदं वातेन सगरेण रक्ष॥ रक्षां धारयामि॥

(ततः त्रिशत्यर्चनं कुर्यात्)

॥ श्रीरुद्रनाम त्रिशती ॥

नमो हिरण्यबाहवे नमः। सेनान्यै नमः। दिशां च पतये नमः। नमो वृक्षेभ्यो नमः। हरिकेशेभ्यो नमः। पशूनां पतये नमः। नमस्सस्पिंजराय नमः। त्विषीमते नमः। पथीनां पतये नमः। नमो बभ्लुशाय नमः। विव्याधिने नमः। अन्नानां पतये नमः। नमो हरिकेशाय नमः। उपवीतिने नमः। पुष्टानां पतये नमः। नमो भवस्य हेत्यै नमः। जगतां पतये नमः। नमो रुद्राय नमः। आततताविने नमः। क्षेत्राणां पतये नमः। नमस्सूताय नमः। अहन्त्याय नमः। वनानां पतये नमः। नमो रोहिताय नमः। स्थपतये

In Public domain. Digitization Muthulakshmi Research Academy

नमः। वृक्षाणां पतये नमः। नमो मन्त्रिणे नमः। वाणिजाय नमः। कक्षाणां पतये नमः। नमो भुवन्तये नमः। वारिवस्कृताय नमः। ओषधीनां पतये नमः। नम उच्चैर्घोषाय नमः। आक्रन्दयते नमः। पत्तीनां पतये नमः। नमः कृत्स्नवीताय नमः। धावते नमः। सत्वनां पतये नमः॥३८॥

नमः सहमानाय नमः। निव्याधिने नमः। आव्याधिनीनां पतये नमः। नमः ककुभाय नमः। निषंगिणे नमः। स्तेनानां पतये नमः। नमो निषंगिणे नमः। इषुधिमते नमः। तस्कराणां पतये नमः। नमो वंचते नमः। परिवंचते नमः। स्तायूनां पतये नमः। नमो निचेरवे नमः। परिचराय नमः। अरण्यानां पतये नमः। नमः सृकाविभ्यो नमः। जिघाꣳसद्भ्यो नमः। मुष्णतां पतये नमः। नमोऽसिमद्भ्यो नमः। नक्तं चरद्भ्यो नमः। प्रकृन्तानां पतये नमः। नमः उष्णीषिणे नमः। गिरिचराय नमः। कुलुंचानां पतये नमः। नम इषुमद्भ्यो नमः। धन्वाविभ्यश्च नमः। वो नमः। नम आतन्वानेभ्यो नमः। प्रतिदधानेभ्यश्च नमः। वो नमः। नम आयच्छद्भ्यो नमः। विसृजद्भ्यश्च नमः। वो नमः। नमोऽस्यद्भ्यो नमः। विध्यद्भ्यश्च नमः। वो नमः। नम आसीनेभ्यो नमः। शयानेभ्यश्च नमः। वो नमः। नमः स्वपद्भ्यो नमः। जाग्रद्भ्यश्च नमः। वो नमः। नमस्तिष्ठद्भ्यो नमः। धावद्भ्यश्च नमः। वो नमः। नमस्सभाभ्यो नमः। सभापतिभ्यश्च नमः। वो नमः। नमो अश्वेभ्यो नमः। अश्वपतिभ्यश्च नमः। वो नमः॥

नम आव्याधिनीभ्यो नमः। विविध्यन्तीभ्यश्च नमः। वो नमः। नम उगणाभ्यो नमः। तृꣳहतीभ्यश्च नमः। वो नमः। नमो गृत्सेभ्यो नमः। गृत्सपतिभ्यश्च नमः। वो नमः। नमो व्रातेभ्यो

In Public domain. Digitization Muthulakshmi Research Academy

नमः। व्रातपतिभ्यश्च नमः। वो नमः। नमो गणेभ्यो नमः। गणपतिभ्यश्च नमः। वो नमः। नमो विरूपेभ्यो नमः। विश्वरूपेभ्यश्च नमः। वो नमः। नमो महद्भ्यो नमः। क्षुल्लकेभ्यश्च नमः। वो नमः। नमो रथिभ्यो नमः। अरथेभ्यश्च नमः। वो नमः। नमो रथेभ्यो नमः। रथपतिभ्यश्च नमः। वो नमः। नमस्सेनाभ्यो नमः। सेनानिभ्यश्च नमः। वो नमः। नमः क्षत्तृभ्यो नमः। संग्रहीतृभ्यश्च नमः। वो नमः। नमस्तक्षभ्यो नमः। रथकारेभ्यश्च नमः। वो नमः। नमः कुलालेभ्यो नमः। कर्मारेभ्यश्च नमः। वो नमः। नमः पुंजिष्टेभ्यो नमः। निषादेभ्यश्च नमः। वो नमः। नम इषुकृद्भ्यो नमः। धन्वकृद्भ्यश्च नमः। वो नमः। नमो मृगयुभ्यो नमः। श्वनिभ्यश्च नमः। वो नमः। नमः श्वभ्यो नमः। श्वपतिभ्यश्च नमः। वो नमः ॥८९॥

नमो भवाय च नमः। रुद्राय च नमः। नमश्शर्वाय च नमः। पशुपतये च नमः। नमो नीलग्रीवाय च नमः। शितिकण्ठाय च नमः। नमः कपर्दिने च नमः। व्युप्तकेशाय च नमः। नमस्सहस्राक्षाय च नमः। शतधन्वने च नमः। नमो गिरिशाय च नमः। शिपिविष्टाय च नमः। नमो मीढुष्टमाय च नमः। इषुमते च नमः। नमो ह्रस्वाय च नमः। वामनाय च नमः। नमो बृहते च नमः। वर्षीयसे च नमः। नमो वृद्धाय च नमः। संवृध्वने च नमः। नमो अग्रियाय च नमः। प्रथमाय च नमः। नम आशवे च नमः। अजिराय च नमः। नमः शीघ्रियाय च नमः। शीभ्याय च नमः। नम ऊर्म्याय च नमः। अवस्वन्याय च नमः। नमः स्रोतस्याय च नमः। द्वीप्याय च नमः ॥१७०॥

नमो ज्येष्ठाय च नमः। कनिष्ठाय च नमः। नमः पूर्वजाय

In Public domain. Digitization Muthulakshmi Research Academy

च नमः। अपरजाय च नमः। नमो मध्यमाय च नमः। अपगल्भाय च नमः। नमो जघन्याय च नमः। बुध्नियाय च नमः। नमः सोभ्याय च नमः। प्रतिसर्याय च नमः। नमो याम्याय च नमः। क्षेम्याय च नमः। नम उर्वर्याय च नमः। खल्याय च नमः। नमः श्लोक्याय च नमः। अवसान्याय च नमः। नमो वन्याय च नमः। कक्ष्याय च नमः। नमश्श्रवाय च नमः। प्रतिश्रवाय च नमः। नम आशुषेणाय च नमः। आशुरथाय च नमः। नमः शूराय च नमः। अवभिन्दते च नमः। नमो वर्मिणे च नमः। वरूथिने च नमः। नमो बिल्मिने च नमः। कवचिने च नमः। नमश्श्रुताय च नमः। श्रुतसेनाय च नमः ॥२००॥

नमो दुन्दुभ्याय च नमः। आहनन्याय च नमः। नमो धृष्णवे च नमः। प्रमृशाय च नमः। नमो दूताय च नमः। प्रहिताय च नमः। नमो निषंगिणे च नमः। इषुधिमते च नमः। नमस्तीक्ष्णेषवे च नमः। आयुधिने च नमः। नमः स्वायुधाय च नमः। सुधन्वने च नमः। नमः स्रुत्याय च नमः। पथ्याय च नमः। नमः काट्याय च नमः। नीप्याय च नमः। नमस्सूद्याय च नमः। सरस्याय च नमः। नमो नाद्याय च नमः। वैशन्ताय च नमः। नमः कूप्याय च नमः। अवट्याय च नमः। नमो वर्ष्याय च नमः। अवर्ष्याय च नमः। नमो मेघ्याय च नमः। विद्युत्याय च नमः। नम ईध्रियाय च नमः। आतप्याय च नमः। नमो वात्याय च नमः। रेष्मियाय च नमः। नमो वास्तव्याय च नमः। वास्तुपाय च नमः ॥२३२॥

नमस्सोमाय च नमः। रुद्राय च नमः। नमस्ताम्राय च नमः। अरुणाय च नमः। नमः शंगाय च नमः। पशुपतये च नमः। नम उग्राय च नमः। भीमाय च नमः। नमो अग्रेवधाय च नमः।

In Public domain. Digitization Muthulakshmi Research Academy

दूरेवधाय च नमः। नमो हन्त्रे च नमः। हनीयसे च नमः। नमो वृक्षेभ्यो नमः। हरिकेशेभ्यो नमः। नमस्ताराय नमः। नमश्शंभवे च नमः। मयोभवे च नमः। नमश्शंकराय च नमः। मयस्कराय च नमः। नमः शिवाय च नमः। शिवतराय च नमः। नमस्तीर्थ्याय च नमः। कूल्याय च नमः। नमः पार्याय च नमः। अवार्याय च नमः। नमः प्रतरणाय च नमः। उत्तरणाय च नमः। नम आतार्याय च नमः। आलाद्याय च नमः। नमः शष्प्याय च नमः। फेन्याय च नमः। नमस्सिकत्याय च नमः। प्रवाह्याय च नमः॥२६५॥

नम इरिण्याय च नमः। प्रपथ्याय च नमः। नमः किंशिलाय च नमः। क्षयणाय च नमः। नमः कपर्दिने च नमः। पुलस्तये च नमः। नमो गोष्ठ्याय च नमः। गृह्याय च नमः। नमस्तल्प्याय च नमः। गेह्याय च नमः। नमः काट्याय च नमः। गह्वरेष्ठाय च नमः। नमो हृदय्याय च नमः। निवेष्प्याय च नमः। नमः पांसव्याय च नमः। रजस्याय च नमः। नमः शुष्क्याय च नमः। हरित्याय च नमः। नमो लोप्याय च नमः। उलप्याय च नमः। नम ऊर्व्याय च नमः। सूर्म्याय च नमः। नमः पर्ण्याय च नमः। पर्णशद्याय च नमः। नमोऽपगुरमाणाय च नमः। अभिघ्नते च नमः। नम आक्खिदते च नमः। प्रक्खिदते च नमः। नमो वो नमः। किरिकेभ्यो नमः। देवानां हृदयेभ्यो नमः। नमो विक्षीणकेभ्यो नमः। नमो विचिन्वत्केभ्यो नमः। नम आनिर्हतेभ्यो नमः। नम आमीवत्केभ्यो नमः॥३००॥

(ततःद्रापेअन्धसस्पत इत्यनुवाकेन प्रदक्षिणं कार्यम्)

★★★

In Public domain. Digitization Muthulakshmi Research Academy

॥ प्रदक्षिणमंत्रः ॥

द्रापे अन्धसस्पते दरिद्रन्नीललोहित। एषां पुरुषाणामेषां पशूनां मा भेर्मारो मो एषां किंचनाममत्॥

या ते रुद्र शिवा तनूः शिवा विश्वाह भेषजी। शिवा रुद्रस्य भेषजी तया नो मृड जीवसे॥

इमाꣳरुद्राय तवसे कपर्दिने क्षयद्वीराय प्रभरामहे मतिम्। यथा नः शमसद्द्विपदे चतुष्पदे विश्वं पुष्टं ग्रामे अस्मिन्ननातुरम्॥

मृडा नो रुद्रोतनो मयस्कृधि क्षयद्वीराय नमसा विधेम ते। यच्छं च योश्च मनुरायजे पिता तदश्याम तव रुद्र प्रणीतौ॥

मा नो महान्तमुत मा नो अर्भकं मा न उक्षन्तमुत मा न उक्षितम्। मा नो वधीः पितरं मोत मातरं प्रिया मा नस्तनुवो रुद्र रीरिषः॥

मानस्तोके तनये मा न आयुषि मा नो गोषु मा नो अश्वेषु रीरिषः। वीरान्मा नो रुद्र भामितोऽवधी हविष्मन्तो नमसा विधेम ते॥

आरात्ते गोघ्न उत पूरुषघ्ने क्षयद्वीराय सुम्नमस्मे ते अस्तु। रक्षा च नो अधि च देव ब्रूह्यधा च नः शर्म यच्छ द्विबर्हाः॥

स्तुहि श्रुतं गर्तसदं युवानं मृगन्न भीम मुपहत्नुमुग्रम्। मृडा जरित्रे रुद्र स्तवानो अन्यन्ते अस्मन्निवपन्तु सेनाः॥

परिणो रुद्रस्य हेतिर्वृणक्तु परि त्वेषस्य दुर्मतिरघायोः। अव स्थिरा मघवद्भ्यस्तनुष्व मीढ्वस्तोकाय तनयाय मृडय॥

मीढुष्टम शिवतम शिवो नः सुमना भव॥ परमे वृक्ष आयुधं निधाय कृत्तिं वसान आचर पिनाकं बिभ्रदागहि॥

In Public domain. Digitization Muthulakshmi Research Academy

विकिरिद विलोहित नमस्ते अस्तु भगवः। यास्ते सहस्र हेतयोऽन्यमस्मन्निवपन्तु ताः॥

सहस्राणि सहस्रधा बाहुवोस्तव हेतयः। तासामीशानो भगवः पराचीना मुखा कृधि॥

(सहस्राणीति मन्त्रैः त्रयोदश नमस्कारान् कुर्यात्)

॥ नमस्कार मंत्रः ॥

सहस्राणि सहस्रशो ये रुद्रा अधि भूम्याम्।
तेषा सहस्रयोजनेऽवधन्वानि तन्मसि। महादेवादिभ्यो नमः॥
अस्मिन् महत्यर्णवेऽन्तरिक्षे भवा अधि।
तेषा सहस्रयोजनेऽवधन्वानि तन्मसि। महादेवादिभ्यो नमः॥
नीलग्रीवाः शितिकण्ठाः शर्वा अधः क्षमाचराः।
तेषा सहस्रयोजनेऽवधन्वानि तन्मसि। महादेवादिभ्यो नमः॥
नीलग्रीवाः शितिकण्ठा दिव रुद्रा उपश्रिताः।
तेषा सहस्रयोजनेऽवधन्वानि तन्मसि। महादेवादिभ्यो नमः॥
ये वृक्षेषु सस्पिंजरा नीलग्रीवा विलोहिताः।
तेषा सहस्रयोजनेऽवधन्वानि तन्मसि। महादेवादिभ्यो नमः॥
ये भूतानामधिपतयो विशिखासः कपर्दिनः।
तेषा सहस्रयोजनेऽवधन्वानि तन्मसि। महादेवादिभ्यो नमः॥
ये अन्नेषु विविध्यन्ति पात्रेषु पिबतो जनान्।
तेषा सहस्रयोजनेऽवधन्वानि तन्मसि। महादेवादिभ्यो नमः॥
ये पथां पथिरक्षय ऐलबृदा यव्युधः।
तेषा सहस्रयोजनेऽवधन्वानि तन्मसि। महादेवादिभ्यो नमः॥
ये तीर्थानि प्रचरन्ति सृकावन्तो निषङ्गिणः।
तेषा सहस्रयोजनेऽवधन्वानि तन्मसि। महादेवादिभ्यो नमः॥

In Public domain. Digitization Muthulakshmi Research Academy

य एतावन्तश्च भूयाꣳसश्च दिशो रुद्रा वितस्थिरे।
तेषाꣳसहस्रयोजनेऽवधन्वानि तन्मसि। महादेवादिभ्यो नमः॥

नमो रुद्रेभ्यो ये पृथिव्यां येषामन्न मिषवस्तेभ्यो दश प्राचीर्दश दक्षिणा दश प्रतीचीर्दशोदीचीर्दशोर्ध्वास्तेभ्यो नमस्ते नो मृडयन्तु ते यं द्विष्मो यश्च नो द्वेष्टि तं वो जम्भे दधामि॥ महादेवादिभ्यो नमः॥

नमो रुद्रेभ्यो येऽन्तरिक्षे येषां वात इषवस्तेभ्यो दश प्राचीर्दश दक्षिणा दश प्रतीचीर्दशोदीचीर्दशोर्ध्वास्तेभ्यो नमस्ते नो मृडयन्तु ते यं द्विष्मो यश्च नो द्वेष्टि तं वो जम्भे दधामि॥ महा देवादिभ्यो नमः॥

नमो रुद्रेभ्यो ये दिवि येषां वर्षमिषव स्तेभ्यो दश प्राचीर्दश दक्षिणा दश प्रतीचीर्दशोदीचीर्दशोर्ध्वास्तेभ्यो नमस्ते नो मृडयन्तु ते यं द्विष्मो यश्च नो द्वेष्टि तं वो जम्भे दधामि॥ महादेवादिभ्यो नमः॥ (ततः समग्रचमकानुवाकैः सर्वाभीष्टं प्रार्थयेत्)।

॥ प्रार्थना — चमकप्रश्नः ॥

अग्नाविष्णू सजोषसेमा वर्द्धन्तु वां गिरः। द्युम्नैर्वाजेभिरागतम्। वाजश्च मे प्रसवश्च मे प्रयतिश्च मे प्रसितिश्च मे धीतिश्च मे क्रतुश्च मे स्वरश्च मे श्लोकश्च मे श्रावश्च मे श्रुतिश्च मे ज्योतिश्च मे सुवश्च मे प्राणश्च मेऽपानश्च मे व्यानश्च मेऽसुश्च मे चित्तं च म आधीतं च मे वाक्च मे मनश्च मे चक्षुश्च मे श्रोत्रं च मे दक्षश्च मे बलं च म ओजश्च मे सहश्च म आयुश्च मे जरा च म आत्मा च मे तनूश्च मे शर्म च मे वर्म च मे ऽङ्गानि च मेऽस्थानि च मे परूꣳषि

In Public domain. Digitization Muthulakshmi Research Academy

च मे शरीराणि च मे॥१॥

ज्यैष्ठ्यं च म आधिपत्यं च मे मन्युश्च मे भामश्च मेऽमश्च मेऽम्भश्च मे जेमा च मे महिमा च मे वरिमा च मे प्रथिमा च मे वर्ष्मा च मे द्राघुया च मे वृद्धं च मे वृद्धिश्च मे सत्यं च मे श्रद्धा च मे जगच्च मे धनं च मे वशश्च मे त्विषिश्च मे क्रीडा च मे मोदश्च मे जातं च मे जनिष्यमाणं च मे सूक्तं च मे सुकृतं च मे वित्तं च मे वेद्यं च मे भूतं च मे भविष्यच्च मे सुगं च मे सुपथं च म ऋद्धं च म ऋद्धिश्च मे क्लृप्तं च मे क्लृप्तिश्च मे मतिश्च मे सुमतिश्च मे॥२॥

शं च मे मयश्च मे प्रियं च मेऽनुकामश्च मे कामश्च मे सौमनसश्च मे भद्रं च मे श्रेयश्च मे वस्यश्च मे यशश्च मे भगश्च मे द्रविणं च मे यन्ता च मे धर्ता च मे क्षेमश्च मे धृतिश्च मे विश्वं च मे महश्च मे संविच्च मे ज्ञात्रं च मे सूश्च मे प्रसूश्च मे सीरं च मे लयश्च म ऋतं च मे ऽमृतं च मे ऽयक्ष्मं च मे ऽनामयच्च मे जीवातुश्च मे दीर्घायुत्वं च मे ऽनमित्रं च मे ऽभयं च मे सुगं च मे शयनं च मे सूषा च मे सुदिनं च मे॥३॥

ऊर्क्च मे सूनृता च मे पयश्च मे रसश्च मे घृतं च मे मधु च मे सग्धिश्च मे सपीतिश्च मे कृषिश्च मे वृष्टिश्च मे जैत्रं च म औद्भिद्यं च मे रयिश्च मे रायश्च मे पुष्टं च मे पुष्टिश्च मे विभु च मे प्रभु च मे बहु च मे भूयश्च मे पूर्णं च मे पूर्णतरं च मेऽक्षितिश्च मे कूयवाश्च मे ऽन्नं च मे ऽक्षुच्च मे व्रीहयश्च मे यवाश्च मे माषाश्च मे तिलाश्च मे मुद्गाश्च मे खल्वाश्च मे गोधूमाश्च मे मसुराश्च मे प्रियंगवश्च मे ऽणवश्च मे श्यामाकाश्च मे नीवाराश्च मे॥४॥

In Public domain. Digitization Muthulakshmi Research Academy

अश्मा॑ च मे॒ मृत्ति॑का च मे गि॒रय॑श्च मे॒ पर्व॑ताश्च मे॒ सिक॑ताश्च
मे॒ वन॒स्पत॑यश्च मे॒ हिर॑ण्यं च॒ मे ऽय॑श्च मे॒ सीसं॑ च मे॒ त्रपु॑श्च मे श्या॒मं
च॑ मे लो॒हं च॑ मे॒ ऽग्निश्च॑ म॒ आप॑श्च मे वी॒रुध॑श्च म॒ ओष॑धयश्च मे
कृष्टप॒च्यं च॑ मे ऽकृष्टप॒च्यं च॑ मे ग्रा॒म्याश्च॑ मे प॒शव॑ आर॒ण्याश्च॑
य॒ज्ञेन॑ कल्पन्तां वि॒त्तं च॑ मे॒ वित्ति॑श्च मे भू॒तं च॑ मे॒ भूति॑श्च मे॒ वसु॑ च
मे वस॒तिश्च॑ मे॒ कर्म॑ च मे॒ शक्ति॑श्च॒ मे ऽर्थ॑श्च म॒ एम॑श्च म॒ इति॑श्च मे॒
गति॑श्च मे ॥५॥

अ॒ग्निश्च॑ म॒ इन्द्र॑श्च मे॒ सोम॑श्च म॒ इन्द्र॑श्च मे सवि॒ता च॑ म॒ इन्द्र॑श्च
मे॒ सर॑स्वती च म॒ इन्द्र॑श्च मे पू॒षा च॑ म॒ इन्द्र॑श्च मे॒ बृह॒स्पति॑श्च म॒ इन्द्र॑श्च
मे मि॒त्रश्च॑ म॒ इन्द्र॑श्च मे॒ वरु॑णश्च म॒ इन्द्र॑श्च मे॒ त्वष्टा॑ च म॒ इन्द्र॑श्च मे
धा॒ता च॑ म॒ इन्द्र॑श्च मे॒ विष्णु॑श्च म॒ इन्द्र॑श्च मे॒ ऽश्विनौ॑ च म॒ इन्द्र॑श्च मे
म॒रुत॑श्च म॒ इन्द्र॑श्च मे॒ विश्वे॑ च मे दे॒वा इन्द्र॑श्च मे पृथि॒वी च॑ म॒ इन्द्र॑श्च
मे॒ ऽन्तरि॑क्षं च म॒ इन्द्र॑श्च मे॒ द्यौश्च॑ म॒ इन्द्र॑श्च मे॒ दिश॑श्च म॒ इन्द्र॑श्च मे
मू॒र्द्धा च॑ म॒ इन्द्र॑श्च मे प्र॒जाप॑तिश्च म॒ इन्द्र॑श्च मे ॥६॥

अ॒ꣳशुश्च॑ मे र॒श्मिश्च॒ मेऽदा॑भ्यश्च॒ मेऽधिप॑तिश्च म उपा॒ꣳशुश्च॑
मेऽन्तर्या॒मश्च॑ म ऐन्द्रवाय॒वश्च॑ मे मैत्रावरु॒णश्च॑ म आश्वि॒नश्च॑ मे
प्रतिप्र॒स्थान॑श्च मे शु॒क्रश्च॑ मे म॒न्थी च॑ म आग्रय॒णश्च॑ मे वैश्वदे॒वश्च॑ मे
ध्रु॒वश्च॑ मे वैश्वान॒रश्च॑ म ऋतुग्र॒हाश्च॑ मे ऽतिग्रा॒ह्या॑श्च म ऐन्द्रा॒ग्नश्च॑ मे
वैश्वदे॒वश्च॑ मे मरुत्व॒तीया॑श्च मे माहे॒न्द्रश्च॑ म आदि॒त्यश्च॑ मे सावि॒त्रश्च॑
मे सारस्व॒तश्च॑ मे पौ॒ष्णश्च॑ मे पात्नीव॒तश्च॑ मे हारियोज॒नश्च॑ मे ॥७॥

In Public domain. Digitization Muthulakshmi Research Academy

इध्मश्च मे बर्हिश्च मे वेदिश्च मे धिष्णियाश्च मे स्रुचश्च मे चमसाश्च मे ग्रावाणश्च मे स्वरवश्च म उपरवाश्च मेऽधिषवणे च मे द्रोणकलशश्च मे वायव्यानि च मे पूतभृच्च म आधवनीयश्च म आग्नीध्रं च मे हविर्धानं च मे गृहाश्च मे सदश्च मे पुरोडाशाश्च मे पचताश्च मेऽवभृथश्च मे स्वगाकारश्च मे॥८॥

अग्निश्च मे घर्मश्च मेऽर्कश्च मे सूर्यश्च मे प्राणश्च मेऽश्वमेधश्च मे पृथिवी च मेऽदितिश्च मे दितिश्च मे द्यौश्च मे शक्वरी रङ्गुलयो दिशश्च मे यज्ञेन कल्पन्तामृक्च मे साम च मे स्तोमश्च मे यजुश्च मे दीक्षा च मे तपश्च म ऋतुश्च मे व्रतं च मेऽहोरात्रयोर्वृष्ट्या बृहद्रथन्तरे च मे यज्ञेन कल्पेताम्॥९॥

गर्भाश्च मे वत्साश्च मे त्र्यविश्च मे त्र्यवी च मे दित्यवाट् च मे दित्यौही च मे पञ्चाविश्च मे पञ्चावी च मे त्रिवत्सश्च मे त्रिवत्सा च मे तुर्यवाट् च मे तुर्यौ ही च मे पष्ठवाच्च मे पष्ठौही च म उक्षा च मे वशा च म ऋषभश्च मे वेहच्च मेऽनड्वाञ्च मे धेनुश्च म आयुर्यज्ञेन कल्पतां प्राणो यज्ञेन कल्पतामपानो यज्ञेन कल्पतां व्यानो यज्ञेन कल्पतां चक्षुर्यज्ञेन कल्पताꣳ श्रोत्रं यज्ञेन कल्पतां मनो यज्ञेन कल्पतां वाग्यज्ञेन कल्पतामात्मा यज्ञेन कल्पतां यज्ञो यज्ञेन कल्पताम्॥१०॥

एका च मे तिस्रश्च मे पञ्च च मे सप्त च मे नव च म एकादश च मे त्रयोदश च मे पंचदश च मे सप्तदश च मे नवदश च म एकविꣳशतिश्च मे त्रयोविꣳशतिश्च मे पंचविꣳशतिश्च मे सप्तविꣳशतिश्च मे नवविꣳशतिश्च म एकत्रिꣳशच्च मे त्रयस्त्रिꣳशच्च मे चतस्रश्च मेऽष्टौ च मे द्वादश च मे षोडश च मे

In Public domain. Digitization Muthulakshmi Research Academy

वि॑ःशुतिश्चं मे चतुर्वि॑ःशतिश्च मेऽष्टावि॑ः शतिश्च मे द्वात्रि॑ःशच्च मे षट्त्रि॑ःशच्च मे चत्वारि॑ःशच्च मे चतुश्चत्वारि॑ःशच्च मेऽष्टाचत्वारि॑ःशच्च मे वाजश्च प्रसवश्चा- पिजश्च क्रतुश्च सुवश्च मूर्द्धा च व्यश्निंयश्चान्त्यायनश्चान्त्यश्च भौवनश्च भुवनश्चाधि पतिश्च॥११॥ महादेवादिभ्यो नमः। समस्तोपचारान्समर्पयामि। (अथास्याघोरस्तनुरुपतिष्ठते)।

अघोरे॑भ्योऽथ घोरे॑भ्यो घोरघोरतरेभ्यः। सर्वे॑भ्य स्सर्व- शर्वे॑भ्यो नमस्ते अस्तु रुद्ररूपेभ्यः॥ तत्पुरुषाय विद्महे महादेवाय धीमहि। तन्नो रुद्रः प्रचोदया॑त्।

ईशान स्सर्व॑विद्याना मीश्वर-स्सर्व॑भूतानां ब्रह्माऽधिपति- र्ब्रह्मणोऽधिपतिर्ब्रह्मा शिवो मे अस्तु सदाशिवोम्॥ (अथाशिषमाशास्ते)

आयुराशा॑स्ते। सुप्रजास्त्व माशा॑स्ते। सजातवनस्यामाशा॑स्ते। उत्तरान्देव यज्यामाशा॑स्ते। भूयो हविष्करण माशा॑स्ते। दिव्यं धामाशा॑स्ते। विश्वं॑ प्रियमाशा॑स्ते। यदनेन हविषाऽऽशा॑स्ते। तद- श्यात्तदृद्ध्यात्। तदस्मै देवारासन्ताम्। तदग्निर्देवो देवेभ्यो वनते। वयमग्नेर्मानुषाः। इष्टं च वीतं च। उभे च नो द्यावापृथिवी अ॑ःहसस्पाताम्। इहगतिर्वामस्येदं च। नमो देवेभ्यः॥

॥ श्रीरुद्रप्रश्नः (न्यासः) ॥

अस्य श्रीरुद्राध्याय प्रश्न महामन्त्रस्य, अघोर ऋषिः, अनुष्टुप् छन्दः, सङ्कर्षणमूर्तिस्वरूपो योऽसावादित्यः परमपुरुषः स एष रुद्रो देवता॥

नमः शिवायेति बीजम्। शिवतरायेति शक्तिः। महा-

In Public domain. Digitization Muthulakshmi Research Academy

देवायेति कीलकम्। श्री सांबसदाशिव प्रसादसिद्ध्यर्थे जपे विनियोगः ॥१॥

ओं अग्निहोत्रात्मने अङ्गुष्ठाभ्यां नमः।

दर्शपूर्णमासात्मने तर्जनीभ्यां नमः।

चातुर्मास्यात्मने मध्यमाभ्यां नमः।

निरूढपशुबन्धात्मने अनामिकाभ्यां नमः।

ज्योतिष्टोमात्मने कनिष्ठिकाभ्यां नमः।

सर्वक्रत्वात्मने करतलकरपृष्ठाभ्यां नमः ॥२॥

अग्निहोत्रात्मने हृदयाय नमः। दर्शपूर्णमासात्मने शिरसे स्वाहा। चातुर्मास्यात्मने शिखायै वषट्। निरूढपशुबन्धात्मने कवचाय हुं। ज्योतिष्टोमात्मने नेत्रत्रयाय वौषट्। सर्वक्रत्वात्मने अस्त्राय फट्। भूर्भुवस्सुवरोमिति दिग्बन्धः।

॥ ध्यानम् ॥

आपाताल नभः स्थलान्त भुवन ब्रह्माण्ड माविस्फुर-
ज्ज्योतिः स्फाटिक लिङ्गमौलि विलसत् पूर्णेन्दुवान्तामृतैः।
अस्तोकाप्लुत मेक मीश मनिशं रुद्रानुवाकाञ्जपन्
ध्यायेदीप्सित सिद्धयेऽद्रुवपदं विप्रोऽभिषिञ्चेच्छिवम् ॥४॥
ब्रह्माण्ड व्याप्तदेहा भसित हिमरुचा भासमाना भुजङ्गैः
कण्ठे कालाः कपर्दाकलित शशिकला श्चण्डकोदण्डहस्ताः।
त्र्यक्षा रुद्राक्षमालाः प्रणत भयहराः शांभवा मूर्ति भेदाः
रुद्राः श्रीरुद्रसूक्तप्रकटित विभवा नः प्रयच्छन्तु सौख्यम् ॥

शं च मे मयश्च मे प्रियंच मेऽनुकामश्च मे कामश्च मे सौमनसश्च मे भद्रं च मे श्रेयश्च मे वस्यश्च मे यशश्च मे भगश्च मे द्रविणं च मे यन्ता च मे धर्ता च मे क्षेमश्च मे धृतिश्च मे विश्वंच मे

In Public domain. Digitization Muthulakshmi Research Academy

महश्च मे संविच्च मे ज्ञात्रं च मे सूश्च मे प्रसूश्च मे सीरं च मे लयश्च म ऋतं च मे ऽमृतं च मेऽयक्ष्मं च मेऽनामयच्च मे जीवातुश्च मे दीर्घायुत्वं च मे ऽनमित्रं च मेऽभयं च मे सुगं च मे शयनं च मे सूषा च मे सुदिनं च मे ॥

ओं शान्तिः शान्तिः शान्तिः ॥

॥ श्रीरुद्रप्रश्नः (नमकम्) ॥

ओं नमो भगवते रुद्राय ॥

नमस्ते रुद्रमन्यव उतोत इषवे नमः। नमस्ते अस्तु धन्वने बाहुभ्यामुत ते नमः ॥ यात इषुः शिवतमा शिवं बभूव ते धनुः। शिवा शरव्या या तव तया नो रुद्र मृडय ॥ या ते रुद्र शिवा तनूरघोराऽपापकाशिनी। तया नस्तनुवा शन्तमया गिरिशंताभिचाकशीहि ॥ यामिषुं गिरिशंत हस्ते बिभर्ष्यस्तवे। शिवां गिरित्र तां कुरु मा हिꣳसीः पुरुषं जगत्! ॥ शिवेन वचसा त्वा गिरिशाच्छा वदामसि। यथा नः सर्वमिज्जगदयक्ष्मꣳसुमना असत् ॥ अध्यवोचदधि वक्ता प्रथमो दैव्यो भिषक्। अहीꣳश्च सर्वाञ्जम्भयन्त्सर्वाश्च यातु धान्यः ॥ असौ यस्ताम्रो अरुण उत बभ्रुः सुमंगलः। ये चेमाꣳरुद्रा अभितो दिक्षु श्रिताः सहस्रशोऽवैषाꣳहेड ईमहे ॥ असौ योऽवसर्पति नीलग्रीवो विलोहितः। उतैनं गोपा अदृशन्नदृशन्नुदहार्यः। उतैनं विश्वा भूतानि स दृष्टो मृडयाति नः ॥ नमो अस्तु नीलग्रीवाय सहस्राक्षाय मीढुषे। अथो ये अस्य सत्त्वानोऽहं तेभ्योऽकरन्नमः ॥ प्रमुंच धन्वनस्त्व मुभयो रार्त्नियोर्ज्याम्। याश्च ते हस्त इषवः परा ता

In Public domain. Digitization Muthulakshmi Research Academy

भगवो वप॥ अवतत्य धनुस्त्वꣳ सहस्राक्ष शतेषुधे। निशीर्य शल्यानां मुखा शिवो नः सुमना भव॥ विज्यं धनुः कपर्दिनो विशल्यो बाणवाꣳ उत। अनेशन्नस्येषव आभुरस्य निषंगथिः॥ या ते हेति मींढुष्टम हस्ते बभूव ते धनुः। तयाऽस्मान्विश्वतस्त्व-मयक्ष्मया परिब्भुज॥ नमस्ते अस्त्वायुधायानातताय धृष्णवे। उभाभ्यामुत ते नमो बाहुभ्यां तव धन्वने॥ परि ते धन्वनो हेति-रस्मान्वृणक्तु विश्वतः। अथो य इषुधिस्तवारे अस्मन्निधेहि तम्॥१॥

नमस्ते अस्तु भगवन् विश्वेश्वराय महादेवाय त्र्यंबकाय त्रिपुरान्तकाय त्रिकाग्नि कालाय कालाग्निरुद्राय नीलकण्ठाय मृत्युंजयाय सर्वेश्वराय सदाशिवाय श्रीमन्महादेवाय नमः॥

नमो हिरण्यबाहवे सेनान्ये दिशां च पतये नमो नमो वृक्षेभ्यो हरिकेशेभ्यः पशूनां पतये नमो नमः सस्पिञ्जराय त्विषीमते पथीनां पतये नमो नमो बभ्लुशाय विव्याधिनेऽन्नानां पतये नमो नमो हरिकेशायोपवीतिने पुष्टानां पतये नमो नमो भवस्य हेत्यै जगतां पतये नमो नमो रुद्रायाततायिने क्षेत्राणां पतये नमो नमः सूतायाहन्त्याय वनानां पतये नमो नमो रोहिताय स्थपतये वृक्षाणां पतये नमो नमो मन्त्रिणे वाणिजाय कक्षाणां पतये नमो नमो भुवंतये वारिवस्कृतायौषधीनां पतये नमो नम उच्चैर्घोषायाक्रन्दयते पत्तीनां पतये नमो नमः कृथ्स्नवीताय धावते सत्त्वनां पतये नमः॥२॥

नमः सहमानाय निव्याधिने आव्याधिनीनां पतये नमो नमः ककुभाय निषङ्गिणे स्तेनानां पतये नमो नमो निषङ्गिण इषुधिमते

In Public domain. Digitization Muthulakshmi Research Academy

तस्कराणां पतये नमो नमो वञ्चते परिवञ्चते स्तायूनां पतये नमो नमो निचेरवे परिचरायारण्यानां पतये नमो नमः सृकाविभ्यो जिघांसद्भ्यो मुष्णतां पतये नमो नमोऽसिमद्भ्यो नक्तं चरद्भ्यः प्रकृन्तानां पतये नमो नम उष्णीषिणे गिरिचराय कुलुञ्चानां पतये नमो नम इषुमद्भ्यो धन्वाविभ्यश्च वो नमो नम आतन्वानेभ्यः प्रतिदधानेभ्यश्च वो नमो नम आयच्छद्भ्यो विसृजद्भ्यश्च वो नमो नमोऽस्यद्भ्यो विद्ध्यद्भ्यश्च वो नमो नम आसीनेभ्यः शयानेभ्यश्च वो नमो नमः स्वपद्भ्यो जाग्रद्भ्यश्च वो नमो नमस्तिष्ठद्भ्यो धावद्भ्यश्च वो नमो नमः सभाभ्यः सभापतिभ्यश्च वो नमो नमो अश्वेभ्योऽश्वपतिभ्यश्च वो नमः ॥३॥

नम आव्याधिनीभ्यो विविध्यन्तीभ्यश्च वो नमो नम उगणाभ्यस्तृंहतीभ्यश्च वो नमो नमो गृत्सेभ्यो गृत्सपतिभ्यश्च वो नमो नमो व्रातेभ्यो व्रातपतिभ्यश्च वो नमो नमो गणेभ्यो गणपतिभ्यश्च वो नमो नमो विरूपेभ्यो विश्वरूपेभ्यश्च वो नमो नमो महद्भ्यः क्षुल्लकेभ्यश्च वो नमो नमो रथिभ्योऽरथेभ्यश्च वो नमो नमो रथेभ्यो रथपतिभ्यश्च वो नमो नमः सेनाभ्यः सेनानिभ्यश्च वो नमो नमः क्षत्तृभ्यः संग्रहीतृभ्यश्च वो नमो नमस्तक्षभ्यो रथकारेभ्यश्च वो नमो नमः कुलालेभ्यः कमरिभ्यश्च वो नमो नमः पुञ्जिष्टेभ्यो निषादेभ्यश्च वो नमो नम इषुकृद्भ्यो धन्वकृद्भ्यश्च वो नमो नमो मृगयुभ्यः श्वनिभ्यश्च वो नमो नमः श्वभ्यः श्वपतिभ्यश्च वो नमः ॥४॥

नमो भवाय च रुद्राय च नमः शर्वाय च पशुपतये च नमो नीलग्रीवाय च शितिकण्ठाय च नमः कपर्दिने च व्युप्तकेशाय च

In Public domain. Digitization Muthulakshmi Research Academy

नमः सहस्राक्षाय च शतधन्वने च नमो गिरिशाय च शिपिविष्टाय च नमो मीढुष्टमाय चेषुमते च नमो ह्रस्वाय च वामनायच नमो बृहते च वर्षीयसे च नमो वृद्धाय च संवृद्ध्वने च नमो अग्रियाय च प्रथमाय च नम आशवे चाजिराय च नमः शीघ्रियाय च शीभ्याय च नम ऊर्म्याय चावस्वन्याय च नमः स्रोतस्याय च द्वीप्याय च॥५॥

नमो ज्येष्ठाय च कनिष्ठाय च नमः पूर्वजाय चापरजाय च नमो मद्ध्यमाय चापगल्भाय च नमो जघन्याय च बुध्नियाय च नमः सोभ्याय च प्रतिसर्याय च नमो याम्याय च क्षेम्याय च नम उर्वर्याय च खल्याय च नमः श्लोक्याय चावसान्याय च नमो वन्याय च कक्ष्याय च नमः श्रवाय च प्रतिश्रवाय च नम आशुषेणाय चाशुरथाय च नमः शूराय चावभिन्दते च नमो वर्मिणे च वरूथिने च नमो बिल्मिने च कवचिने च नमः श्रुताय च श्रुतसेनाय च॥६॥

नमो दुन्दुभ्याय चाहनन्याय च नमो धृष्णवे च प्रमृशाय च नमो दूताय च प्रहिताय च नमो निषङ्गिणे चेषुधिमते च नमस्तीक्ष्णेषवे चायुधिने च नमः स्वायुधाय च सुधन्वने च नमः स्रुत्याय च पथ्याय च नमः काट्याय च नीप्याय च नमः सूद्याय च सरस्याय च नमो नाद्याय च वैशन्ताय च नमः कूप्याय चाऽवट्याय च नमो वर्ष्याय चावर्ष्याय च नमो मेघ्याय च विद्युत्याय च नम ईध्रियाय चाऽऽतप्याय च नमो वात्याय च रेष्मियाय च नमो वास्तव्याय च वास्तुपाय च॥७॥

नमः सोमाय च रुद्राय च नमस्ताम्राय चारुणाय च नमः

In Public domain. Digitization Muthulakshmi Research Academy

शङ्गाय च पशुपतये च नम उग्राय च भीमाय च नमो अग्रेवधाय च दूरेवधाय च नमो हन्त्रे च हनीयसे च नमो वृक्षेभ्यो हरिकेशेभ्यो नमस्ताराय नमः शंभवे च मयोभवे च नमः शंकराय च मयस्कराय च नमः शिवाय च शिवतराय च नमस्तीर्थ्याय च कूल्याय च नमः पार्याय चाऽवार्याय च नमः प्रतरणाय चोत्तरणाय च नम आतार्याय चालाद्याय च नमः शष्प्याय च फेन्याय च नमः सिकत्याय च प्रवाह्याय च ॥८॥

नम इरिण्याय च प्रपथ्याय च नमः किꣳशिलाय च क्षयणाय च नमः कपर्दिने च पुलस्तये च नमो गोष्ठ्याय च गृह्याय च नमस्तल्प्याय च गेह्याय च नमः काट्याय च गह्वरेष्ठाय च नमो हृद्य्याय च निवेष्प्याय च नमः पाꣳसव्याय च रजस्याय च नमः शुष्क्याय च हरित्याय च नमो लोप्याय चोलप्याय च नम ऊर्व्याय च सूर्म्याय च नमः पर्ण्याय च पर्णशद्याय च नमोऽपगुरमाणाय चाभिघ्नते च नम आक्खिदते च प्रक्खिदते च नमो वः किरिकेभ्यो देवानाꣳ हृदयेभ्यो नमो विक्षीणकेभ्यो नमो विचिन्वत्केभ्यो नम आनिर्हतेभ्यो नम आमीवत्केभ्यः ॥९॥

द्रापे अन्धसस्पते दरिद्रन्नीललोहित। एषां पुरुषाणामेषां पशूनां मा भेर्मारो मो एषां किंचनाममत्॥ या ते रुद्र शिवा तनूः शिवा विश्वाह भेषजी। शिवा रुद्रस्य भेषजी तया नो मृड जीवसे॥ इमाꣳरुद्राय तवसे कपर्दिने क्षयद्वीराय प्रभरामहे मतिम्। यथा नः शमसद्द्विपदे चतुष्पदे विश्वं पुष्टं ग्रामे अस्मिन्ननातुरम्॥ मृडा नो रुद्रोतनो मयस्कृधि क्षयद्वीराय नमसा विधेम ते। यच्छं च योश्च मनुरायजे पिता तदश्याम तव रुद्र

In Public domain. Digitization Muthulakshmi Research Academy

प्रणीतौ॥ मा नौ महान्तमुत मा नौ अर्भकं मा न उक्षन्त मुत मा न उक्षितम्। मा नौ वधीः पितरं मोत मातरं प्रिया मा नस्तनुवौ रुद्र रीरिषः॥ मानस्तोके तनये मा न आयुषि मा नो गोषु मा नो अश्वेषु रीरिषः। वीरान्मा नौ रुद्र भामितोऽवधीर्हविष्मन्तो नमसा विधेम ते॥ आरात्ते गोघ्न उत पूरुषघ्ने क्षयद्वीराय सुम्नमस्मे तै अस्तु। रक्षा च नो अधि च देव ब्रूह्यधा च नः शर्म यच्छ द्विबर्हाः॥ स्तुहि श्रुतं गर्तसदं युवानं मृगन्न भीम मुपहत्नुमुग्रम्। मृडा जरित्रे रुद्र स्तवानो अन्यन्तै अस्मन्निवपन्तु सेनाः॥ परिणो रुद्रस्य हेतिर्वृणक्तु परि त्वेषस्य दुर्मतिरघायोः। अव स्थिरा मघवद्भ्यस्तनुष्व मीढ्वस्तोकाय तनयाय मृडय॥ मीढुष्टम शिवतम शिवो नः सुमना भव॥ परमे वृक्ष आयुधं निधाय कृत्तिं वसान आचर पिनाकं बिभ्रदागहि॥ विकिरिद विलोहित नमस्ते अस्तु भगवः। यास्ते सहस्रꣳहेतयोऽन्यमस्म न्निवपन्तु ताः॥ सहस्राणि सहस्रधा बाहुवोस्तव हेतयः। तासामीशानो भगवः पराचीना मुखा कृधि॥१०॥

सहस्राणि सहस्रशो ये रुद्रा अधि भूम्याम्। तेषाꣳसहस्रयोजनेऽवधन्वानि तन्मसि॥ अस्मिन् महत्यर्णवे-ऽन्तरिक्षे भवा अधि॥ नीलग्रीवाः शितिकण्ठाः शर्वा अधः क्षमाचराः॥ नीलग्रीवाः शितिकण्ठा दिवꣳरुद्रा उपश्रिताः॥ ये वृक्षेषु सस्पिंजरा नीलग्रीवा विलोहिताः॥ ये भूतानामधिपतयो विशिखासः कपर्दिनः॥ ये अन्नेषु विविद्ध्यन्ति पात्रेषु पिबतो जनान्॥ ये पथां पथिरक्षय ऐलबृदा यव्युधः॥ ये तीर्थानि प्रचरन्ति सृकावन्तो निषङ्गिणः॥ य एतावन्तश्च भूयाꣳसश्च दिशो रुद्रा

In Public domain. Digitization Muthulakshmi Research Academy

वितस्थिरे। तेषा ँसहस्त्र योजने ऽवधन्वानि तन्मसि॥ नमो रुद्रेभ्यो ये पृथिव्यां येऽन्तरिक्षे ये दिवि येषामन्नं वातो वर्षमिषव स्तेभ्यो दश प्राचीर्दश दक्षिणा दश प्रतीचीर्दशो-दीचीर्दशोर्ध्वास्तेभ्यो नमस्ते नो मृडयन्तु ते यं द्विष्मो यश्च नो द्वेष्टि तं वो जम्भे दधामि॥

त्र्यंबकं यजामहे सुगन्धिं पुष्टिवर्द्धनम्। उर्वारुकमिव बन्धनान्मृत्यो र्मुक्षीय माऽमृतात्॥

यो रुद्रो अग्नौ यो अप्सु य ओषधीषु यो रुद्रो विश्वा भुवनाऽऽविवेश तस्मै रुद्राय नमो अस्तु॥

तमुष्टुहिय: स्विषु: सुधन्वा यो विश्वस्य क्षयति भेषजस्य। यक्ष्वामहे सौमनसाय रुद्रं नमोभि र्देवमसुरं दुवस्य॥

अयं मे हस्तो भगवानयं मे भगवत्तर:। अयं मे विश्व-भेषजोऽय ँ शिवाभिमर्शन:॥

ये ते सहस्त्रमयुतं पाशा मृत्यो मर्त्याय हन्तवे। तान् यज्ञस्य मायया सर्वानव यजामहे। मृत्यवे स्वाहा मृत्यवे स्वाहा॥

ओं नमो भगवते रुद्राय विष्णवे मृत्युर्मे पाहि। प्राणानां ग्रन्थिरसि रुद्रो मा विशान्तक:। तेनान्नेनाप्यायस्व॥ नमो रुद्राय विष्णवे मृत्युर्मे पाहि॥११॥

ओं शान्ति: शान्ति: शान्ति:॥

इति श्रीकृष्णयजुर्वेदीय तैत्तिरीय संहितायां चतुर्थकाण्डे पंचम: प्रपाठक:॥

★★★

In Public domain. Digitization Muthulakshmi Research Academy

॥ चमकप्रश्नः ॥

अग्नाविष्णू सजोषसेमा वर्द्धन्तु वां गिरः। द्युम्नै र्वाजेभिरागतम्। वाजश्च मे प्रसवश्च मे प्रयतिश्च मे प्रसितिश्च मे धीतिश्च मे क्रतुश्च मे स्वरश्च मे श्लोकश्च मे श्रावश्च मे श्रुतिश्च मे ज्योतिश्च मे सुवश्च मे प्राणश्च मेऽपानश्च मे व्यानश्च मेऽसुश्च मे चित्तं च म आधीतं च मे वाक्च मे मनश्च मे चक्षुश्च मे श्रोत्रं च मे दक्षश्च मे बलं च म ओजश्च मे सहश्च म आयुश्च मे जरा च म आत्मा च मे तनूश्च मे शर्म च मे वर्म च मेऽङ्गानि च मेऽस्थानि च मे परूꣳषि च मे शरीराणि च मे॥१॥

ज्यैष्ठ्यं च म आधिपत्यं च मे मन्युश्च मे भामश्च मेऽमश्च मेऽम्भश्च मे जेमा च मे महिमा च मे वरिमा च मे प्रथिमा च मे वर्ष्मा च मे द्राघुया च मे वृद्धं च मे वृद्धिश्च मे सत्यं च मे श्रद्धा च मे जगच्च मे धनं च मे वशश्च मे त्विषिश्च मे क्रीडा च मे मोदश्च मे जातं च मे जनिष्यमाणं च मे सूक्तं च मे सुकृतं च मे वित्तं च मे वेद्यं च मे भूतं च मे भविष्यच्च मे सुगं च मे सुपथं च म ऋद्धं च म ऋद्धिश्च मे क्लृप्तं च मे क्लृप्तिश्च मे मतिश्च मे सुमतिश्च मे॥२॥

शं च मे मयश्च मे प्रियं च मेऽनुकामश्च मे कामश्च मे सौमनसश्च मे भद्रं च मे श्रेयश्च मे वस्यश्च मे यशश्च मे भगश्च मे द्रविणं च मे यन्ता च मे धर्ता च मे क्षेमश्च मे धृतिश्च मे विश्वं च मे महश्च मे संविच्च मे ज्ञात्रं च मे सूश्च मे प्रसूश्च मे सीरं च मे लयश्च म ऋतं च मेऽमृतं च मेऽयक्ष्मं च मेऽनामयच्च मे जीवातुश्च मे

In Public domain. Digitization Muthulakshmi Research Academy

दीर्घायुत्वं च मे ऽनमित्रं च मे ऽभयं च मे सुगं च मे शयनं च मे सूषा च मे सुदिनं च मे ॥३॥

ऊर्क्च मे सूनृता च मे पयश्च मे रसश्च मे घृतं च मे मधु च मे सग्धिश्च मे सपीतिश्च मे कृषिश्च मे वृष्टिश्च मे जैत्रं च म औद्भिद्यं च मे रयिश्च मे रायश्च मे पुष्टं च मे पुष्टिश्च मे विभु च मे प्रभु च मे बहु च मे भूयश्च मे पूर्णं च मे पूर्णतरं च मेऽक्षितिश्च मे कूयवाश्च मे ऽन्नं च मे ऽक्षुच्च मे व्रीहयश्च मे यवाश्च मे माषाश्च मे तिलाश्च मे मुद्गाश्च मे खल्वाश्च मे गोधूमाश्च मे मसुराश्च मे प्रियंगवश्च मे ऽणवश्च मे श्यामाकाश्च मे नीवाराश्च मे ॥४॥

अश्मा च मे मृत्तिका च मे गिरयश्च मे पर्वताश्च मे सिकताश्च मे वनस्पतयश्च मे हिरण्यं च मे ऽयश्च मे सीसं च मे त्रपुश्च मे श्यामं च मे लोहं च मे ऽग्निश्च म आपश्च मे वीरुधश्च म ओषधयश्च मे कृष्टपच्यं च मे ऽकृष्टपच्यं च मे ग्राम्याश्च मे पशव आरण्याश्च यज्ञेन कल्पन्तां वित्तं च मे वित्तिश्च मे भूतं च मे भूतिश्च मे वसु च मे वसतिश्च मे कर्म च मे शक्तिश्च मे ऽर्थश्च म एमश्च म इतिश्च मे गतिश्च मे ॥५॥

अग्निश्च म इन्द्रश्च मे सोमश्च म इन्द्रश्च मे सविता च म इन्द्रश्च मे सरस्वती च म इन्द्रश्च मे पूषा च म इन्द्रश्च मे बृहस्पतिश्च म इन्द्रश्च मे मित्रश्च म इन्द्रश्च मे वरुणश्च म इन्द्रश्च मे त्वष्टा च म इन्द्रश्च मे धाता च म इन्द्रश्च मे विष्णुश्च म इन्द्रश्च मे ऽश्विनौ च म इन्द्रश्च मे मरुतश्च म इन्द्रश्च मे विश्वे च मे देवा इन्द्रश्च मे पृथिवी च म इन्द्रश्च

In Public domain. Digitization Muthulakshmi Research Academy

मे ऽन्तरिक्षं च म इन्द्रश्च मे द्यौश्च म इन्द्रश्च मे दिशश्च म इन्द्रश्च मे मूर्द्धा च म इन्द्रश्च मे प्रजापतिश्च म इन्द्रश्च मे ॥६॥

अꣳशुश्च मे रश्मिश्च मेऽदाभ्यश्च मेऽधिपतिश्च म उपाꣳशुश्च मेऽन्तर्यामश्च म ऐन्द्रवायवश्च मे मैत्रावरुणश्च म आश्विनश्च मे प्रतिप्रस्थानश्च मे शुक्रश्च मे मन्थी च म आग्रयणश्च मे वैश्वदेवश्च मे ध्रुवश्च मे वैश्वानरश्च म ऋतुग्रहाश्च मे ऽतिग्राह्याश्च म ऐन्द्राग्नश्च मे वैश्वदेवश्च मे मरुत्वतीयाश्च मे माहेन्द्रश्च म आदित्यश्च मे सावित्रश्च मे सारस्वतश्च मे पौष्णश्च मे पात्नीवतश्च मे हारियोजनश्च मे ॥७॥

इध्मश्च मे बर्हिश्च मे वेदिश्च मे धिष्णियाश्च मे स्रुचश्च मे चमसाश्च मे ग्रावाणश्च मे स्वरवश्च म उपरवाश्च मे ऽधिषवणे च मे द्रोणकलशश्च मे वायव्यानि च मे पूतभृच्च म आधवनीयश्च म आग्नीध्रं च मे हविर्द्धानं च मे गृहाश्च मे सदश्च मे पुरोडाशाश्च मे पचताश्च मेऽवभृथश्च मे स्वगाकारश्च मे ॥८॥

अग्निश्च मे घर्मश्च मे ऽर्कश्च मे सूर्यश्च मे प्राणश्च मे ऽश्वमेधश्च मे पृथिवी च मे ऽदितिश्च मे दितिश्च मे द्यौश्च मे शक्वरी रङ्गुलयो दिशश्च मे यज्ञेन कल्पन्ता मृक्च मे साम च मे स्तोमश्च मे यजुश्च मे दीक्षा च मे तपश्च म ऋतुश्च मे व्रतं च मे ऽहोरात्रयो र्वृष्ट्या बृहद्रथन्तरे च मे यज्ञेन कल्पेताम् ॥९॥

गर्भाश्च मे वत्साश्च मे त्र्यविश्च मे त्र्यवी च मे दित्यवाट् च मे दित्यौही च मे पञ्चाविश्च मे पञ्चावी च मे त्रिवत्सश्च मे त्रिवत्सा च मे तुर्यवाट् च मे तुर्यौ ही च मे पष्ठवाच्च मे पष्ठौही च म उक्षा च मे वशा च म ऋषभश्च मे वेहच्च

In Public domain. Digitization Muthulakshmi Research Academy

मेऽनड्वाञ्च मे धेनुश्च म आयुर्यज्ञेन कल्पतां प्राणो यज्ञेन कल्पता मपानो यज्ञेन कल्पतां व्यानो यज्ञेन कल्पतां चक्षुर्यज्ञेन कल्पता॑ श्रोत्रं यज्ञेन कल्पतां मनो यज्ञेन कल्पतां वाग्यज्ञेन कल्पता मात्मा यज्ञेन कल्पतां यज्ञो यज्ञेन कल्पताम्॥१०॥

एका च मे तिस्रश्च मे पञ्च च मे सप्त च मे नव च म एकादश च मे त्रयोदश च मे पंचदश च मे सप्तदश च मे नवदश च म एकविंशतिश्च मे त्रयोविंशतिश्च मे पंचविंशतिश्च मे सप्तविंशतिश्च मे नवविंशतिश्च म एकत्रिंशच्च मे त्रयस्त्रिंशच्च मे चतस्रश्च मेऽष्टौ च मे द्वादश च मे षोडश च मे विंशतिश्च मे चतुर्विंशतिश्च मेऽष्टाविंशतिश्च मे द्वात्रिंशच्च मे षट्त्रिंशच्च मे चत्वारिंशच्च मे चतुश्चत्वारिंशच्च मेऽष्टाचत्वारिंशच्च मे वाजश्च प्रसवश्चापिजश्च क्रतुश्च सुवश्च मूर्द्धा च व्यश्नियश्चान्त्याय नश्चान्त्यश्च भौवनश्च भुवनश्चाधि-पतिश्च॥११॥

इडा देवहूर्मनु र्यज्ञनी बृहस्पतिरुक्थामदानि शंसिष-द्विश्वेदेवाः सूक्तवाचः पृथिवि मातर्मा मा हिंसी-र्मधु मनिष्ये मधु जनिष्ये मधु वक्ष्यामि मधु वदिष्यामि मधुमतीं देवेभ्यो वाच-मुद्यासंशुश्रूषेण्यां मनुष्येभ्यस्तं मा देवा अवन्तु शोभायै पितरोऽनुमदन्तु॥

ॐ शान्तिः शान्तिः शान्तिः॥

(रुद्रजपानन्तरं चमकस्य एकानुवाकस्य जापः। प्रति जपान्ते पूजा। महादेवादिभ्यो नमः। बलाय नमः—धूपमाघ्रापयामि॥ बल प्रमथनाय नमः दीपं सन्दर्शयामि॥ सर्वभूतदमनाय नमः। नैवेद्यम्॥ मनोन्मनाय नमः कर्पूर ताम्बूलम्॥ ततः नीराजनम्)॥

★★★

In Public domain. Digitization Muthulakshmi Research Academy

॥ कर्पूर नीराजन मन्त्राः ॥

(प्रत्येक चमकानुवाक जपानन्तरं धूपं, दीपं नैवेद्यं समर्प्य नीराजनं कुर्यात्)

हꣳस श्शुचिष द्वसु रन्तरिक्षस द्धोता वेदिषदतिथि र्दुरोणसत्।
नृष द्वरस दृतस द्व्योमस दब्जा गोजा ऋतजा अद्रिजा ऋतं बृहत्॥१॥
घृतं मिमिक्षिरेन्घृतमस्ययोनि र्घृतेश्रितो घृत मुवस्य धाम।
अनुष्वधमावह मादयस्व स्वाहाकृतं वृषभ वक्षि हव्यम्॥२॥
समुद्रा दूर्मिर्मधुमाꣳउदार दुपाꣳशुना सममृतत्व मानट्।
घृतस्य नाम गुह्यं यदस्ति जिह्वा देवाना ममृतस्य नाभिः॥३॥
वयं नाम प्रब्रवामा घृतेनास्मिन् यज्ञे धारयामा नमोभिः।
उप ब्रह्मा शृणव च्छस्यमानं चतुश्शृङ्गोऽवमीद्गौरएतत्॥४॥
चत्वारि शृङ्गा त्रयो अस्य पादा द्वे शीर्षे सप्त हस्तासो अस्य।
त्रिधाबद्धो वृषभो रोरवीति महो देवो मर्त्याꣳ आविवेश॥५॥
त्रिधाहितं पणिभि र्गुह्यमानं गवि देवासो घृतमन्वविन्दन्।
इन्द्र एकꣳ सूर्य एकं जजान वेना देकꣳ स्वधयानिष्ट तक्षुः॥६॥
यो देवानाँ प्रथमं पुरस्ताद्विश्वाधियो रुद्रो महर्षिः।
हिरण्यगर्भं पश्यत जायमानꣳ सनो देव श्शुभया स्मृत्या स्संयुनक्तु॥७॥
यस्मात्परं नापरमस्ति किंचि-द्यस्मान्नाणीयो न ज्यायोँऽस्ति कश्चित्।
वृक्ष इव स्तब्धो दिवि तिष्ठत्येकस्तेनेदं पूर्णं पुरुषेण सर्वम्॥८॥
न कर्मणा न प्रजया धनेन त्यागेनैके अमृतत्व मानशुः।
परेण नाकं निहितं गुहायां विभ्राजदेतद्यतयो विशन्ति॥९॥
वेदान्तविज्ञान सुनिश्चितार्था स्संन्यास योगाद्यतयश्शुद्ध सत्त्वाः।
ते ब्रह्मलोकेतु परान्तकाले परामृतात्परिमुच्यन्ति सर्वे॥१०॥

In Public domain. Digitization Muthulakshmi Research Academy

दह्रं विपापं परमेऽश्मभूतं यत्पुण्डरीकं पुरमध्यस्ँस्थम्।
तत्रापि दह्रं गगनं विशोकस्तस्मिन् यदन्तस्तदुपासितव्यम्।
यो वेदादौ स्वरः प्रोक्तो वेदान्ते च प्रतिष्ठितः।
तस्य प्रकृतिलीनस्य यः परस्स महेश्वरः॥११॥

॥ गायत्री मन्त्राः॥

१. तत्पुरुषाय विद्महे महादेवाय धीमहि। तन्नो रुद्रः प्रचोदयात्॥

२. तत्पुरुषाय विद्महे वक्र तुण्डाय धीमहि। तन्नो दन्तिः प्रचोदयात्॥

३. तत्पुरुषाय विद्महे चक्र तुण्डाय धीमहि। तन्नो नन्दिः प्रचोदयात्॥

४. तत्पुरुषाय विद्महे महा सेनाय धीमहि। तन्न ष्षणमुखः प्रचोदयात्॥

५. तत्पुरुषाय विद्महे सुवर्ण पक्षाय धीमहि। तन्नो गरुडः प्रचोदयात्॥

६. वेदात्मनाय विद्महे हिरण्य गर्भाय धीमहि। तन्नो ब्रह्मः प्रचोदयात्॥

७. नारायणाय विद्महे वासुदेवाय धीमहि। तन्नो विष्णुः प्रचोदयात्॥

८. वज्रनखाय विद्महे तीक्ष्ण दँष्ट्राय धीमहि। तन्नो नारसिँहः प्रचोदयात्॥

९. भास्कराय विद्महे महद्द्युतिकराय धीमहि। तन्नो आदित्यः प्रचोदयात्॥

In Public domain. Digitization Muthulakshmi Research Academy

१०. वैश्वानराय विद्महे लालीलाय धीमहि। तन्नो अग्निः प्रचोदयात्॥

११. कात्यायनाय विद्महे कन्यकुमारि धीमहि। तन्नो दुर्गिः प्रचोदयात्॥

॥ प्रार्थना-अर्घ्यम् साद्गुण्यम् ॥

१. प्रतिवारं शतरुद्रीय जपान्ते चमकप्रश्नस्य एकैकं अनुवाकं च जपेयुः।

२. यजमानः प्रतिवारं वक्ष्यमाणैः मन्त्रैः देवं संप्रार्थ्य, अर्घ्यदानं कृत्वा, साद्गुण्यार्थं आचार्याय फलादिदानं च कुर्यात्।

प्रथमवारजपान्ते—

यस्तु रुद्रं जपेन्नित्यं ध्यायन् देवं महेश्वरम्।
यश्च सागरपर्यन्तां सशैलवनकाननाम्॥
दद्यात् काञ्चनसंयुक्तां भूमिमोषधिसंयुताम्।
तस्मादप्यधिकं पुण्यं तस्य रुद्रजपाद्भवेत्।
इति रुद्राध्यायमाहात्म्यं अनुसन्धाय।
दशपञ्चसुनेत्राढ्यं पञ्चशीर्षसमन्वितम्।
दशहस्तं शुभाकारं महादेवमहं भजे॥
इति स्तुत्वा। वक्ष्यमाणैः श्लोकैः अर्घ्यदानं कुर्यात्॥

॥ अर्घ्यश्लोकाः ॥

शम्भो ब्रह्मशिरश्छेदिन् ब्रह्माण्डालयनायक।
नम उग्र महाभाग प्रथमार्घ्यं गृहाण भोः॥१॥
महादेवाय नमः इदमर्घ्यं।
वेदान्तागम सिद्धान्त यज्ञेश परमेश्वर।
समस्त जगदाधार द्वितीयार्घ्यं गृहाण भोः॥२॥

In Public domain. Digitization Muthulakshmi Research Academy

महादेवाय नमः इदमर्घ्यं।

सर्वस्वातन्त्र्य साम्राज्य सर्वयज्ञफलप्रद।
दयालो भक्तसंरक्षक तृतीयार्घ्यं गृहाण भोः ॥३॥

महादेवाय नमः इदमर्घ्यं।

ब्रह्मादिभिः सुरैस्सर्वैः स्तूयमानपदांबुज।
अम्बिकारमण स्वामिन् तुरीयार्घ्यं गृहाण भोः ॥४॥

महादेवाय नमः इदमर्घ्यं।

अनेन प्रथमवार रुद्रजपेन श्री महादेवः प्रीयताम्। इति प्रथमावृत्तौ।

अथवा

प्रथमवाररुद्रजपान्ते—यस्तु रुद्रं जपेन्नित्यं ध्यायमानो महेश्वरम्। यश्च सागरपर्यन्तां सशैल वनकाननाम्। दद्यात्काञ्च-संयुक्तां भूमिमोषधिसंयुताम्। तस्मादप्यधिक पुण्यं तस्यरुद्रजपाद् भवेत्॥

अर्घ्यदानम्—महादेव महानन्द धीदेव्या सहितानघ इदमर्घ्यं प्रदास्यामि सर्वपापापनुत्तये। धीदेवी समेत महादेवाय नमः। इदमर्घ्य मिदमर्घ्य मिदर्घ्यम्। अनेन अर्घ्यप्रदानेन महादेवः प्रीयताम्॥

फलदानम्—हिरण्यगर्भ + मे। इदं फलं सदक्षिणाकं सताम्बूलं धीदेवीसमेत श्रीमहादेव प्रीतिं कामय मान स्तुभ्यमहं सम्प्रददे। नमम।

अनेन प्रथमवार श्री रुद्रजपेन भगवान् महादेवः सुप्रीतः सुप्रसन्नो वरदोभूत्वा सर्वेषां महाजनानां जन्म जन्मान्तर कृत दुरित निवृत्तिप्रदो भूयादिति भवन्तो महान्तोऽनुगृह्णन्तु॥

In Public domain. Digitization Muthulakshmi Research Academy

२. द्वितीयवारजपान्ते

सुरापः स्वर्णहारीच रुद्रजापी जले स्थितः।
सहस्त्रशीर्षाजापीच मुच्यते सर्वकिल्बिषैः ॥
शूलवर्य धरं देवं शिवं विषमलोचनम्।
अक्षमालाधरं शंभुं वन्दे डमरु धारिणम्॥

पूर्ववद् अर्घ्यदानादिः-

शम्भो ब्रह्मशिरश्छेदिन् ब्रह्माण्डालयनायक।
नम उग्र महाभाग प्रथमार्घ्यं गृहाण भोः ॥१॥
शिवाय नमः इदमर्घ्यं।

वेदान्तागमसिद्धान्त यज्ञेश परमेश्वर।
समस्तजगदाधार द्वितीयार्घ्यं गृहाण भोः ॥२॥
शिवाय नमः इदमर्घ्यं।

सर्वस्वातन्त्र्य साम्राज्य सर्वयज्ञफलप्रद।
दयालो भक्तसंरक्ष तृतीयार्घ्यं गृहाण भोः ॥३॥
शिवाय नमः इदमर्घ्यं।

ब्रह्मादिभिः सुरैस्सर्वैः स्तूयमानपदांबुज।
अम्बिकारमण स्वामिन् तुरीयार्घ्यं गृहाण भोः ॥४॥
शिवाय नमः इदमर्घ्यं।

अनेन द्वितीयवार रुद्र जपेन श्री शिवः प्रीयताम्॥

अथवा

द्वितीयवार जपान्ते—सुरापः स्वर्णहारी च रुद्रजापी जलेस्थितः। सहस्त्रशीर्षाजापी च मुच्यते सर्वकिल्विषैः॥

शूलवर्य धरं देवं शिवं विषमलोचनं।
अक्षमाला धरं शम्भुं वन्दे डमरुधारिणम्॥

॥अर्घ्यदानम्॥

शिवाय परिपूर्णाय सर्वरोगनिवृत्तये।
वृत्तिदेवीसमेताय तुभ्यमर्घ्यं ददाम्यहम्॥

In Public domain. Digitization Muthulakshmi Research Academy

वृत्ति देवी समेत शिवाय नमः। इदमर्घ्यम् +++
अनेन अर्घ्यप्रदानेन शिवः प्रीयताम्
फलदानम्॥ हिरण्यगर्भ+। इदं फलं... सम्प्रददे। नमम॥
अनेन द्वितीयवारः ... वृत्तिदेवी समेतः भगवान् शिवः सुप्रीतः सुप्रसन्नो वरदो भूत्वा सर्वेषां महाजनानां आध्यात्मिक आधिभौतिक आधिदैविक तापत्रयनिवृत्तिद्वारा समस्त मंगलावाप्तिप्रदोभूयादिति... अनुगृह्णन्तु॥

३. तृतीयवारजपान्ते

स्तेयं कृत्वा गुरुदारांश्च गत्वा मद्यं पीत्वा ब्रह्महत्यां च कृत्वा।

भस्मच्छन्नो भस्मशय्याशयानो रुद्राध्यायीमुच्यते सर्वपापैः॥

कालाग्नि रूपिणं रुद्रं जटामकुट मण्डितम्।
त्र्यक्षं चतुर्भुजं देवं नमामि शिरसा विभुम्॥

पूर्ववत् अर्घ्यदानादिः-

शम्भो ब्रह्मशिरश्छेदिन् ब्रह्माण्डालयनायक।
नम उग्र महाभाग प्रथमार्घ्यं गृहाण भोः॥१॥
रुद्राय नमः इदमर्घ्यं।

वेदान्तागमसिद्धान्त यज्ञेश परमेश्वर।
समस्तजगदाधार द्वितीयार्घ्यं गृहाण भोः॥२॥
रुद्राय नमः इदमर्घ्यं।

सर्वस्वातन्त्र्य साम्राज्य सर्वयज्ञफलप्रद।
दयालो भक्तसंरक्ष तृतीयार्घ्यं गृहाण भोः॥३॥
रुद्राय नमः इदमर्घ्यं।

In Public domain. Digitization Muthulakshmi Research Academy

ब्रह्मादिभिः सुरैस्सर्वैः स्तूयमानपदांबुज।
अम्बिकारमण स्वामिन् तुरीयार्घ्यं गृहाण भोः ॥४॥
रुद्राय नमः इदमर्घ्यं।
अनेन तृतीय वार रुद्र जपेन श्री रुद्रः प्रीयताम् ॥

अथवा

तृतीयवार जपान्ते—स्तेयं कृत्वा गुरुदारांश्च गत्वा मद्यं पीत्वा ब्रह्महत्यां च कृत्वा। भस्मच्छन्नो भस्मशय्याशयानो रुद्राध्यायी मुच्यते सर्वपापैः ॥

कालाग्निरुपिणं रुद्रं जटामकुट मण्डितम्।
त्र्यक्षं चतुर्भुजं देवं नमामि शिरसा विभुम्।
तृतीयवार... फलदानञ्चकरिष्ये।

अर्घ्यम्—रुद्राय च नमस्तुभ्यं उशनापतये नमः। प्रसीदार्घ्यं प्रदास्यामि सर्वशत्रुनिवृत्तये।

उशना देवी समेत श्रीरुद्राय नमः। इदमर्घ्यम् (४)।
अनेनार्घ्य प्रदानेन श्रीरुद्रः प्रीयताम् ॥
फलदानम्—हिरण्यगर्भ....। इदं फलं.... सम्प्रददे। नमम।

अनेन तृतीयवार श्रीरुद्रजपेन उशनादेवी समेत भगवान् श्रीरुद्रः सुप्रीतः सुप्रसन्नो वरदो भूत्वा। सर्वेषां महाजनानां शरीरे वर्त्तमानवर्त्तिष्य माण पीडोपद्रव निवर्त्तको भूयादितिः.... अनुगृह्णन्तु ॥

४. तुरीयवारजपान्ते

वेदमेकगुणं जप्त्वा तदह्नैव विशुध्यति।
सर्वपापहराह्येषा रुद्रैकादशिनी तथा ॥

In Public domain. Digitization Muthulakshmi Research Academy

शंकरं शान्तवदनं वराभय विशोभितम्।
लोकानां शोकहन्तारं चन्द्रचूडमहं भजे॥

पूर्ववत् अर्घ्यदानादिः-

शम्भो ब्रह्मशिरश्छेदिन् ब्रह्माण्डालयनायक।
नम उग्र महाभाग प्रथमार्घ्यं गृहाण भोः॥१॥
शंकराय नमः इदमर्घ्यं।

वेदान्तागमसिद्धान्त यज्ञेश परमेश्वर।
समस्तजगदाधार द्वितीयार्घ्यं गृहाण भोः॥२॥
शंकराय नमः इदमर्घ्यं।

सर्वस्वातन्त्र्य साम्राज्य सर्वयज्ञफलप्रद।
दयालो भक्तसंरक्ष तृतीयार्घ्यं गृहाण भोः॥३॥
शंकराय नमः इदमर्घ्यं।

ब्रह्मादिभिः सुरैस्सर्वैः स्तूयमानपदांबुज।
अम्बिकारमण स्वामिन् तुरीयार्घ्यं गृहाण भोः॥४॥
शंकराय नमः इदमर्घ्यं।

अनेन तुरीयवार रुद्र जपेन श्री शंकरः प्रीयताम्॥

अथवा

(४) तुरीयवारजपान्ते—वेदमेकगुणं जप्त्वा तदह्नैव विशुध्यति। सर्वपापहराह्येषा रुद्रैकादशिनी तथा॥ शंकरं शान्तवदनं वराभय विशोभितम्। लोकानां शोकहन्तारं चन्द्रचूडमहं भजे॥

अर्घ्यम्—शंकराय नमस्तुभ्यं उमादेवीयुताय च प्रसीदार्घ्यं प्रदास्यामि व्याधिपीडा निवृत्तये॥ उमादेवी समेत शंकराय नमः। इदमर्घ्यम्। (४)

अनेनार्घ्यप्रदानेन श्री शंकरः प्रीयताम्।

फलदानम्—हिरण्यगर्भ++। इदं फलं... उमादेवी समेत

In Public domain. Digitization Muthulakshmi Research Academy

श्री शंकरप्रीतिंकामयमानः तुभ्यमहं सम्प्रददे। नमम॥

अनेन तुरीयवार श्रीरुद्रजपेन उमादेवी समेत भगवान् शंकरः सुप्रीतः सुप्रसन्नो वरदो भूत्त्वा सर्वेषां महाजनानाम् अनुदिन-मुपचीयमान कल्याणपरम्पराप्रदः भूयादिति भवन्तो...... अनुगृह्णन्तु॥

५. पञ्चमवारजपान्ते

एकादशगुणान्वाऽपि रुद्रानावर्त्य धर्मवित्।
महापापैरपि स्पृष्टो मुच्यते नात्र संशयः॥
त्र्यक्षं चतुर्भुजं शान्तं सुन्दरं नीललोहितम्।
पद्मासनस्थं देवेशं नमामि वृषवाहनम्॥

पूर्ववत् अर्घ्यदानादिः-

शम्भो ब्रह्मशिरश्छेदिन् ब्रह्माण्डालयनायक।
नम उग्र महाभाग प्रथमार्घ्यं गृहाण भोः॥१॥
नीललोहिताय नमः इदमर्घ्यं।
वेदान्तागमसिद्धान्त यज्ञेश परमेश्वर।
समस्तजगदाधार द्वितीयार्घ्यं गृहाण भोः॥२॥
नीललोहिताय नमः इदमर्घ्यं।
सर्वस्वातन्त्र्य साम्राज्य सर्वयज्ञफलप्रद।
दयालो भक्तसंरक्ष तृतीयार्घ्यं गृहाण भोः॥३॥
नीललोहिताय नमः इदमर्घ्यं।
ब्रह्मादिभिः सुरैस्सर्वैः स्तूयमानपदांबुज।
अम्बिकारमण स्वामिन् तुरीयार्घ्यं गृहाण भोः॥४॥
नीललोहिताय नमः इदमर्घ्यं।

अनेन पंचमवार रुद्र जपेन श्री नीललोहितः प्रीयताम्॥

अथवा

(५) पञ्चमवार जपान्ते—एकादशगुणान्वापि रुद्रानावर्त्य

In Public domain. Digitization Muthulakshmi Research Academy

धर्मवित्। महापापैरपिस्पृष्टो मुच्यते नात्रसंशयः। त्र्यक्षं चतुर्भुजं शान्तं सुन्दरं नीललोहितम्। पद्मासनस्थं देवेशं नमामिवृषवाहनम्॥

अर्घ्यम्—नीललोहित विश्वेश नियुद्देवी युतप्रभो। इदमर्घ्यं गृहाण त्वं दुष्टग्रहनिवृत्तये॥ नियुद्देवी समेत नीललोहिताय नमः। इदमर्घ्यम्॥(४)

अनेन अर्घ्यप्रदानेन नीललोहितः प्रीयताम्॥

फलदानम्—हिरण्यगर्भ++॥ इदं फलं सदक्षिणाकं सताम्बूलं नियुद्देवी समेत श्रीनीललोहित प्रीतिं कामयमान स्तुभ्यमहं सम्प्रददे॥ नमम॥

अनेन पंचमवार श्रीरुद्रजपेन नियुद्देवी समेत भगवान् नीललोहितः..... सर्वेषां महाजनानां अरोगदृढगात्रतासिद्धिप्रदो भूयादि..... अनुगृह्णन्तु॥

६. षष्ठवारजपान्ते

महादेवं हृदि ध्यायन् यस्तु रुद्रं जपेत्पुमान्।
सतेनैव हि देहेन रुद्रस्सञ्जायते ध्रुवम्॥
ईशानं देवदेवेशं प्रणमामि सदाशिवम्।
रुद्राक्षमालाभरणं गंगाचन्द्रकलाधरम्॥

पूर्ववत् अर्घ्यदानादिः-

शम्भो ब्रह्मशिरश्छेदिन् ब्रह्माण्डालयनायक।
नम उग्र महाभाग प्रथमार्घ्यं गृहाण भोः॥१॥
ईशानाय नमः इदमर्घ्यं।
वेदान्तागमसिद्धान्त यज्ञेश परमेश्वर।
समस्तजगदाधार द्वितीयार्घ्यं गृहाण भोः॥२॥
ईशानाय नमः इदमर्घ्यं।

In Public domain. Digitization Muthulakshmi Research Academy

सर्वस्वातन्त्र्य साम्राज्य सर्वयज्ञफलप्रद।
दयालो भक्तसंरक्ष तृतीयार्घ्यं गृहाण भोः ॥३॥
ईशानाय नमः इदमर्घ्यं।
ब्रह्मादिभिः सुरैश्वर्यैः स्तूयमानपदांबुज।
अम्बिकारमण स्वामिन् तुरीयार्घ्यं गृहाण भोः ॥४॥
ईशानाय नमः इदमर्घ्यं।
अनेन षष्ठवार रुद्र जपेन श्री ईशानः प्रीयताम्॥

अथवा

(६) षष्ठवार जपान्ते—महादेवं हृदिध्यायन् यस्तु रुद्रं जपेत्युमान्।

सतेनैव हि देहेन रुद्रः संजायते ध्रुवम्॥
ईशानं देव देवेशं प्रणमामि सदाशिवम्।
रुद्राक्षमालाभरणं गंगाचन्द्रकलाधरम्॥
अर्घ्यम्—ईशान सर्वविद्यानां सर्पिदेवीपते प्रभो।
सा गृह्यणार्घ्यं नमस्तेऽस्तु सर्वविद्याफलप्रदम्॥
इदमर्घ्यम्॥(४)
अनेन अर्घ्य प्रदानेन ईशानः प्रीयताम्॥

फलदानम्—हिरण्यगर्भ+॥ इदंफलं सदक्षिणाकं सताम्बूलं सर्पिर्देवी समेत श्री ईशान प्रीतिं कामयमानस्तुभ्यमहं सम्प्रददे। अनेन षष्ठवार श्रीरुद्रजपेन सर्पिर्देवी समेतः भगवान् ईशानस्सुप्रीतस्सुप्रसन्नो वरदोभूत्वा सर्वेषां महाजनानां साम्बशिवचरणारविन्दयोः अचञ्चल भक्तिप्रदोभूयादिति भवन्तो महान्तौऽनुगृह्णन्तु॥

७. सप्तमवारजपान्ते

नमकं चमकं चैव पौरुषं सूक्तमेव च।

In Public domain. Digitization Muthulakshmi Research Academy

नित्यंत्रयं प्रयुञ्जानः शिवलोके महीयते॥
भजेऽहं सुन्दराकारं विजयं फाललोचनम्।
जटामण्डल संयुक्तं भक्तानां भीतिनाशनम्॥

पूर्ववत् अर्घ्यदानादिः-

शम्भो ब्रह्मशिरश्छेदिन् ब्रह्माण्डालयनायक।
नम उग्र महाभाग प्रथमार्घ्यं गृहाण भोः॥१॥
विजयाय नमः इदमर्घ्यं।
वेदान्तागमसिद्धान्त यज्ञेश परमेश्वर।
समस्तजगदाधार द्वितीयार्घ्यं गृहाण भोः॥२॥
विजयाय नमः इदमर्घ्यं।
सर्वस्वातन्त्र्य साम्राज्य सर्वयज्ञफलप्रद।
दयालो भक्तसंरक्ष तृतीयार्घ्यं गृहाण भोः॥३॥
विजयाय नमः इदमर्घ्यं।
ब्रह्मादिभिः सुरैस्सर्वैः स्तूयमानपदांबुज।
अम्बिकारमण स्वामिन् तुरीयार्घ्यं गृहाण भोः॥४॥
विजयाय नमः इदमर्घ्यं।
अनेन सप्तम वार रुद्र जपेन श्री विजयः प्रीयताम्॥

अथवा

(७) सप्तमवार जपान्ते—नमकं चमकं चैव पौरुषं सूक्तमेव च नित्यं त्रयं प्रयुञ्जानः शिवलोके महीयते॥

भजेऽहं सुन्दराकारं विजयं फाललोचनम्।
जटामण्डलसंयुक्तं भक्तानां भीति नाशनम्॥
अर्घ्यम्—विजयाय नमस्तुभ्यं विश्वेशेळापते प्रभो।
मयादत्तं गृहणार्घ्यं सर्वकाम समृद्धये॥
इळादेवीसमेत विजयाय नमः। इदमर्घ्यम्॥ (४)
अनेन अर्घ्यप्रदानेन विजयः प्रीयताम्॥

In Public domain. Digitization Muthulakshmi Research Academy

फलदानम्—हिरण्यगर्भ......। इदं फलं सदक्षिणाकं सताम्बूलम् इलादेवी समेत श्री विजयप्रीतिं कामयमानस्तुभ्यमहं सम्प्रददे। नमम॥ अनेन सप्तमवार श्रीरुद्रजपेन इळादेवी समेत भगवान् विजयः सुप्रीतस्सुप्रसन्नो वरदो भूत्त्वा सर्वेषां महाजनानां सर्वानुकूल्यप्रदो भूयादिति...... अनुगृह्णन्तु॥

८. अष्टमवारजपान्ते :-

नमकं चमकं चैव जपन्तं पौरुषं तथा।
प्रविशेत्स महादेवो गृहं गृहपतिर्यथा॥
भीममिन्दुकलाभूषं पापिनां भीषणाकृतिम्।
वरदं त्रिपुरारातिं वरायुधधरं भजे॥

पूर्ववत् अर्घ्यदानादिः-

शम्भो ब्रह्मशिरश्छेदिन् ब्रह्माण्डालयनायक।
नम उग्र महाभाग प्रथमार्घ्यं गृहाण भोः॥१॥
भीमाय नमः इदमर्घ्यं।
वेदान्तागमसिद्धान्त यज्ञेश परमेश्वर।
समस्तजगदाधार द्वितीयार्घ्यं गृहाण भोः॥२॥
भीमाय नमः इदमर्घ्यं।
सर्वस्वातन्त्र्य साम्राज्य सर्वयज्ञफलप्रद।
दयालो भक्तसंरक्ष तृतीयार्घ्यं गृहाण भोः॥३॥
भीमाय नमः इदमर्घ्यं।
ब्रह्मादिभिः सुरैस्सर्वैः स्तूयमानपदांबुज।
अम्बिकारमण स्वामिन् तुरीयार्घ्यं गृहाण भोः॥४॥
भीमाय नमः इदमर्घ्यं।
अनेन अष्टम वार रुद्र जपेन श्री भीमः प्रीयताम्॥

अथवा

(८) अष्टमवार जपान्ते—

नमकं चमकं चैव जपन्तं पौरुषं तथा।

In Public domain. Digitization Muthulakshmi Research Academy

प्रविशेत्समहादेवो गृहंगृहपतिर्यथा॥
भीममिन्दु कलाभूषं पापिनां भीषणाकृतिम्।
वरदं त्रिपुरारातिं वरायुधधरं भजे॥
अर्घ्यम्—भीमरूपाय पापानाम भीमाय महात्मनाम्।
अंबिकापतये तुभ्यं ददेऽर्घ्यं भयशान्तये॥
अम्बिकादेवी समेत भीमाय नमः। इदमर्घ्यम्॥(४)
अनेन अर्घ्यप्रदानेन भीमः प्रीयताम्।

फलदानम्—हिरण्यगर्भ....। .....अम्बिकादेवी समेत श्री भीमप्रीतिं कामयमानस्तुभ्यमहं सम्प्रददे। न मम॥

अनेन अष्टमवार श्रीरुद्रजपेन अम्बिकादेवी समेत भगवान् भीमः सुप्रीतः सुप्रसन्नोवरदो भूत्त्वा सर्वेषां महाजनानां वर्त्तमानैश्वर्यद्वारा इतोऽपि महदैश्वर्याप्तिप्रदो भूयादिति भवन्तो महान्तोऽनुगृह्णन्तु॥

९. नवमवारजपान्ते

भस्मदिग्ध शरीरस्तु भस्मशायी जितेन्द्रियः।
सततं रुद्रजापी यस्सपरां मुक्तिमाप्नुयात्॥
देवदेवं देवसेव्यं वराभयविशोभितम्।
भक्तकांक्षित दातारं पार्वतीशमहं भजे॥

पूर्ववत् अर्घ्यदानादिः-

शम्भो ब्रह्मशिरश्छेदिन् ब्रह्माण्डालयनायक।
नम उग्र महाभाग प्रथमार्घ्यं गृहाण भोः॥१॥
देवदेवाय नमः इदमर्घ्यं।
वेदान्तागमसिद्धान्त यज्ञेश परमेश्वर।
समस्तजगदाधार द्वितीयार्घ्यं गृहाण भोः॥२॥
देवदेवाय नमः इदमर्घ्यं।
सर्वस्वातन्त्र्य साम्राज्य सर्वयज्ञफलप्रद।
दयालो भक्तसंरक्ष तृतीयार्घ्यं गृहाण भोः॥३॥

In Public domain. Digitization Muthulakshmi Research Academy

देवदेवाय नमः इदमर्घ्यं।

ब्रह्मादिभिः सुरैस्सर्वैः स्तूयमानपदांबुज।
अम्बिकारमण स्वामिन् तुरीयार्घ्यं गृहाण भोः ॥४॥

देवदेवाय नमः इदमर्घ्यं।

अनेन नवम वार रुद्र जपेन श्री देवदेवः प्रीयताम्॥

अथवा

(९) नवमवार जपान्ते—

भस्मदिग्ध शरीरस्तु भस्मशायी जितेन्द्रियः।
सततं रुद्रजापी यस्सपरां मुक्तिमाप्नुयात्॥
देवदेवं देवसेव्यं वराभयविशोभितम्।
भक्तकांक्षित दातारं पार्वतीशमहं भजे॥
अर्घ्यम्—देवदेव महादेव प्रपन्नार्तिहराव्यय।
इरावतीप्राणानाथ ददेऽर्घ्यं पुत्राभिवृद्धये॥
इरादेवी समेत देवदेवाय नमः। इदमर्घ्यम्॥ (४)
अनेन अर्घ्यप्रदानेन देवदेवः प्रीयताम्॥

फलदानम्—हिरण्यगर्भ.....। इदं फलं सदक्षिणाकं सताम्बूलं इरादेवी समेत श्री देवदेव प्रीतिं कामयमानस्तुभ्यमहं सम्प्रददे। नमम।

अनेन नवमवार श्रीरुद्रजपेन इरादेवी समेतः भगवान् देवदेवः सुप्रीतः सुप्रसन्नो वरदो भूत्वा सर्वेषां महाजनानां भगवत्सारूप्यप्रदो भूयादिति भवन्तो महान्तोऽनुगृह्णन्तु॥

१०. दशमवारजपान्ते

रोगवान् पापवांश्चैव रुद्रं जप्त्वा जितेन्द्रियः।
रोगात् पापाच्च मुच्येत रुद्रलोकं च गच्छति॥
भवं सर्वार्थदं देवं पुत्रपौत्र फलप्रदम्।
धर्मार्थकाममोक्षाणां भजे दातारमीश्वरम्॥

In Public domain. Digitization Muthulakshmi Research Academy

पूर्ववत् अर्घ्यदानादिः-

शम्भो ब्रह्मशिरश्छेदिन् ब्रह्माण्डालयनायक।
नम उग्र महाभाग प्रथमार्घ्यं गृहाण भोः ॥१॥
भवाय नमः इदमर्घ्यं।
वेदान्तागमसिद्धान्त यज्ञेश परमेश्वर।
समस्तजगदाधार द्वितीयार्घ्यं गृहाण भोः ॥२॥
भवाय नमः इदमर्घ्यं।
सर्वस्वातन्त्र्य साम्राज्य सर्वयज्ञफलप्रद।
दयालो भक्तसंरक्ष तृतीयार्घ्यं गृहाण भोः ॥३॥
भवाय नमः इदमर्घ्यं।
ब्रह्मादिभिः सुरैस्सर्वैः स्तूयमानपदांबुज।
अम्बिकारमण स्वामिन् तुरीयार्घ्यं गृहाण भोः ॥४॥
भवाय नमः इदमर्घ्यं।
अनेन दशमवार रुद्र जपेन श्री भवः प्रीयताम्॥

अथवा

(१०) दशमवार जपान्ते—
रोगवान् पापवांश्चैव रुद्रंजप्त्वा जितेन्द्रियः।
रोगात्पापाच्च मुच्येत रुद्रलोकं च गच्छति॥
भवं भवार्थदं देवं पुत्र पौत्र फलप्रदम्।
धर्मार्थकाममोक्षाणां भजे दातारमीश्वरम्॥
अर्घ्यम्—भवोद्भव नमस्तेऽस्तु सुधया सहितानध।
भक्त्याहं प्रददाम्यर्घ्यं सदा मङ्गल भावना॥
सुधादेवी समेत भवोद्भवाय नमः। इदमर्घ्यम्॥(४)
अनेन अर्घ्यप्रदानेन भवोद्भवः प्रीयताम्॥

फलदानम्—हिरण्यगर्भ......। इदं फलं सदक्षिणाकं सताम्बूलं सुधादेवी समेत श्रीभव प्रीतिं कामयमानः तुभ्यमहं सम्प्रददे। नमम॥

In Public domain. Digitization Muthulakshmi Research Academy

अनेन दशमवार श्रीरुद्रजपेन सुधादेवी समेत भगवान् भव स्सुप्रीतः सुप्रसन्नः वरदोभूत्वा अस्य यजमानस्य गृहेवसतां द्विपदां चतुष्पदां च नीरोगत्व सिद्धिप्रदः भूयादिति भवन्तो महान्तोऽनुगृह्णन्तु॥

११. एकादशवारजपान्ते

रुद्राध्यायी वसेद्यत्र ग्रामे वा नगरेऽपिवा।
न भवेत्तत्र दुर्भिक्षं आधयो व्याधयोऽपि वा॥
उद्भवं शान्तहृदयं नेत्रत्रयविराजितम्।
प्रसन्नवदनं वन्दे जटामण्डल मण्डितम्॥

पूर्ववत् अर्घ्यदानादिः-

शम्भो ब्रह्मशिरश्छेदिन् ब्रह्माण्डालयनायक।
नम उग्र महाभाग प्रथमार्घ्यं गृहाण भोः॥१॥
उद्भवाय नमः इदमर्घ्यं।
वेदान्तागमसिद्धान्त यज्ञेश परमेश्वर।
समस्तजगदाधार द्वितीयार्घ्यं गृहाण भोः॥२॥
उद्भवाय नमः इदमर्घ्यं।
सर्वस्वातन्त्र्य साम्राज्य सर्वयज्ञफलप्रद।
दयालो भक्तसंरक्ष तृतीयार्घ्यं गृहाण भोः॥३॥
उद्भवाय नमः इदमर्घ्यं।
ब्रह्मादिभिः सुरैश्वर्यैः स्तूयमानपदांबुज।
अम्बिकारमण स्वामिन् तुरीयार्घ्यं गृहाण भोः॥४॥
उद्भवाय नमः इदमर्घ्यं।
अनेन एकादश वार रुद्र जपेन श्री उद्भवः प्रीयताम्॥

अथवा

(११) एकादशवार जपान्ते—रुद्राध्यायी वसेद्यत्र ग्रामेवा नगरेऽपि वा। न भवेत्तत्र दुर्भिक्ष माधयो व्याधयोऽपि वा। उद्भवं शान्त हृदयं नेत्रत्रय विराजितम्। प्रसन्नवदनं वन्दे जटामण्डल-

In Public domain. Digitization Muthulakshmi Research Academy

मण्डितम्॥

अर्घ्यम्—आदित्यात्मक रुद्रेश जगत्प्रेरक धूर्जटे।
गृहाणार्घ्यं मया दत्तं दीक्षा देव्या सहप्रभो॥
दीक्षादेवी समेत उद्भवाय नमः। इदमर्घ्यम्॥(४)
अनेन अर्घ्यप्रदानेन उद्भवः प्रीयताम्॥

फलदानम्—हिरण्यगर्भ.....। इदं फलं सदक्षिणाकं सताम्बूलं दीक्षादेवी समेत उद्भवप्रीतिं कामयमानः तुभ्यमहं सम्प्रददे॥

फलदानम्—हिरण्यगर्भ....। इदं फलं सदक्षिणाकं सताम्बूलं दीक्षादेवी समेत उद्भव (आदित्यात्मक रुद्र) प्रीतिं कामयमानस्तुभ्यमहं सम्प्रददे॥ नमम॥

अनेन एकादशवार श्रीरुद्रजपेन भगवान् सर्वात्मकः असौयस्ताम्र इति निर्दिष्टः आबाल गोप विदित नामा सर्वमङ्गलायतनः आदित्यात्मकः श्रीरुद्रः सुप्रीतः सुप्रसन्नः अभीष्टवरप्रदो भूत्त्वा सर्वेषां महाजनानां तापत्रयनिवृत्तिप्रदः, अपमृत्यु निवृत्तिप्रदः, रोगपीडा निवृत्तिप्रदः, दीर्घायुष्य सिद्धिप्रदः समस्तमङ्गलावाप्ति प्रदश्च भूयादिति भवन्तः महान्तः अनुगृह्णन्तु॥

(निधन पतये नमः।.......। परमलिंगाय नमः धूपमाघ्रापयामि। दीपं दर्शयामि। नैवेद्यं निवेदयामि। कदली फलं निवेदयामि। आचमनीयम् ताम्बूलं॥ नीराजनम्॥)

॥ रुद्रजपानन्तर प्रार्थना स्वस्ति मन्त्राः ॥

(१) यस्य निश्वसितं वेदाः यो वेदेभ्योऽखिलं जगत्।
निर्ममे तमहं वन्दे विद्यातीर्थ महेश्वरं॥

अद्यास्मिन् संवत्सरे दिनत्रये क्रियमाणे (श्री महारुद्राख्य/रुद्रैकादशिन्याख्य/अतिरुद्राख्य) महायज्ञे अद्य (प्रथमे/द्वितीये/तृतीये) दिवसे वयं सच्चिदानन्द भोग्य भोक्तृवर्ग भोगोपकरण-

In Public domain. Digitization Muthulakshmi Research Academy

भोगस्थान परिपूर्ण निखिल सृष्टि स्थिति संहार कर्तारं, नित्य-निरवद्य निरतिशयौ ज्ज्वल्य सौगन्ध्य सौकुमार्य लावण्य कल्य।ण गुणगणनिधिं, वाङ्मनसाऽपरिच्छेद्य स्वरूप स्वभावं, स्वतेजसा नित्यनिवृत्त मायागुणप्रवाहं, अनवधिकाऽतिशय तेजसा निखिलं जगद्भासयन्तं आत्मकान्त्या विश्वमाप्याययन्तं भगवन्तं पुनः पुनः नमस्कृत्वा एतावत् प्रार्थयामहे।

यदनेन प्रथमवार रुद्रजपेन आदित्यात्मकः शिवंकरः महादेवः सुप्रसन्नो वरदो भूत्वा—

"योगक्षेमो नः कल्पतामित्याह।
कल्पते ह वै तत्र प्रजाभ्यो योगक्षेमः।
यत्रैतेन यज्ञेन यजन्ते॥"
"सर्वे भवन्तु सुखिनः सर्वे सन्तु निरामयाः।
सर्वे भद्राणि पश्यन्तु मा कश्चिद् दुःखमाप्नुयात्॥"

इत्यादि श्रुति स्मृति उक्तप्रकारेण पर्जन्यः कामं वर्षित्वा मही मङ्गलभूयिष्ठा सर्वकामदुघा च भूत्वा सर्वे आस्तिक महाजनाः क्षेम स्थैर्य वीर्य विजय आयुरारोग्य ऐश्वर्यादिभिः समन्विताः ईश्वरचिन्तया रममाणाः भूयासुः इति॥

तदवाप्त्यर्थं श्रीमन्तः भवन्तः सम्यगनुगृह्णन्तु।

(२) अनेन द्वितीयवार रुद्रजपेन 'शिव' इति विख्यातः आदित्यात्मकः श्रीरुद्रः सुप्रसन्नो वरदो भूत्वा—

"नमः शंभवे च मयोभवे च नमः शंकराय च मयस्कराय च नमः शिवाय च शिवतराय च"॥

"यद्द्व्यक्षरं नाम गिरेरितं नृणां सकृत्प्रसङ्गादघमाशु हन्ति तत्"॥

"यः शिवो नामरूपाभ्यां या देवी सर्वमङ्गला। तयोः संस्मरणात् पुंसां सर्वतो जयमङ्गलं॥"

In Public domain. Digitization Muthulakshmi Research Academy

इत्यादि श्रुति स्मृति उद्घोषित महिम्नः अस्य परमेश्वरस्य अनुग्रहेण उमा महेश्वर पार्षदाः सर्वे लोकपालकाः सर्वेषां आस्तिकमहाजनानां क्षेमकारकाः भूत्वा तापत्रयविनाशकाः समस्तमङ्गलावाप्तिप्रदाश्च

भूयासुः इति भवन्तः महान्तः सम्यग् अनुगृह्णन्तु।

(३) अनेन तृतीयवार रुद्रजपेन रुद्र इति विख्यातः आदित्यात्मकः श्रीपरमेश्वरः सुप्रसन्नो वरदो भूत्वा—

"यो रुद्रो अग्नौ यो अप्सु य ओषधीषु यो रुद्रो विश्वा भुवनाविवेश तस्मै रुद्राय नमो अस्तु।

"विद्यासु श्रुतिरुत्कृष्टा रुद्रैकादशिनी श्रुतौ।"

इत्यादि श्रुति स्मृति विख्यापितेन श्रीरुद्रं नित्यं जपतां कुलानि सत्पुत्र पौत्रैः अलङ्कृतानि भूत्वा कुलधर्मेण च तानि कुलानि सर्वोत्कृष्टानि दीप्तिमन्ति च भूयासुरिति श्रीरुद्रजपेन अतिपुण्यभाजः भवन्तः वेदविदः सम्यगनुगृह्णन्तु।

(४) अनेन तुरीयवार रुद्रजपेन 'शंकरः' इति विख्यातः आदित्यात्मकः श्रीरुद्रः सुप्रसन्नो वरदो भूत्वा—

"चरणं पवित्रं विततं पुराणम्। येन पूतस्तरति दुष्कृतानि॥"

तेन पवित्रेण शुद्धेन पूताः अतिपाप्मानमरातिं तरेम॥

"स्वर्गापवर्गयोः पुंसां रसायां भुवि संपदाम्।

सर्वासामपि सिद्धीनां मूलं तच्चरणार्चनम्॥

इत्यादि उद्घोषित महिमा पवित्रकीर्तिः श्रीशंकरः सर्वेषां आस्तिकमहाजनानां शान्तिप्रदः शम-दमादि यम-नियमप्रदः दीर्घायुष्यसिद्धिप्रदश्च भूत्वा अस्य पादारविन्दयोः आपत्सु

In Public domain. Digitization Muthulakshmi Research Academy

सम्पत्सु वा अचञ्चल भक्तिप्रदश्च भूयादिति भवन्तः अनुगृह्णन्तु॥

(५) अनेन पञ्चम वार रुद्रजपेन नीललोहित इति कीर्तिमवाप्तः आदित्यात्मकः श्रीरुद्रः सुप्रसन्नो वरदो भूत्वा—

"न तत्र सूर्यो भाति न चन्द्रतारकं नेमा विद्युतो भान्ति कुतोऽयमग्निः।
तमेव भान्तमनुभाति सर्वं तस्य भासा सर्वमिदं विभाति॥
"यदादित्यगतं तेजो जगद्भासयतेऽखिलं
यच्चन्द्रमसि यच्चाग्नौ तत्तेजो विद्धि मामकम्॥"

इत्यादि श्रुति स्मृति वाक्यैः प्रथितस्य भगवतः अनुग्रहेण अस्मिन् भारतवर्षे विविध धर्मान् आचरन्तः महाजनाः परस्परस्पर्धां त्यक्त्वा "एक एव भगवान् विविधरूपेण विराजते" इति ज्ञात्वा मैत्रीभावेन स्वजन्मसाफल्यार्थं लोकक्षेमार्थं च प्रवर्त्तन्ताम् इति भवन्तः श्रीमन्तः सम्यग् अनुगृह्णन्तु॥

(६) अनेन षष्ठवार रुद्रजपेन ईशान इति श्रुति स्मृतिपुराणेषु बहुधा स्तुतः आदित्यात्मकः श्रीरुद्रः सुप्रसन्नो वरदो भूत्वा—

"शतमिन्नु शरदो अन्ति देवा यत्रा नश्चक्रा जरसं तनूनाम्।
पुत्रासो यत्र पितरो भवन्ति मानोमध्यारीरिषदायुर्गन्तोः॥
"तेषां सततयुक्तानां भजतां प्रीतिपूर्वकम्।
ददामि बुद्धियोगं तं येन मामुपयान्ति ते॥

इत्यादि उक्तप्रकारेण अस्य ईशानस्य कारुण्यातिरेकात् तद्भक्तेषु दीर्घायुष्यसिद्धिप्रदः वेदान्तचिन्तनमुखरित सद्बुद्धि प्रदश्च भूयादिति भवन्तः अनुगृह्णन्तु॥

(७) अनेन सप्तमवार रुद्रजपेन विजयरूपः आदित्यात्मकः श्रीरुद्रः सुप्रसन्नो वरदो भूत्वा—

In Public domain. Digitization Muthulakshmi Research Academy

"मम॑ दे॒वा वि॑ह॒वे स॑न्तु सर्व॒ इन्द्रा॑वन्तो म॒रुतो॒ विष्णु॑र॒ग्निः।
मम॒न्तरि॑क्षमु॒रु गो॒पम॑स्तु मह्यं॒ वात॑ः पवतां॒ कामे॑ अ॒स्मिन्।
मयि॑दे॒वा द्रवि॑ण॒माय॑जन्तां॒ मय्या॒शीर॑स्तु मयि॑ दे॒वहू॑तिः"॥

इति वेदप्रतिपादित प्रार्थनाऽनुसारेण अस्य परमेश्वरस्य भक्तेषु सर्वे देवाः सर्वभावेन प्रीताः भूत्वा सुखप्रवर्तकाः, धर्माऽविरुद्धकार्येषु विजयप्रदाश्च भूयासुरिति महान्तः भवन्तः "यावती॒ वै दे॒वता॒स्ताः सर्वा॑ वेद॒विदि ब्राह्म॒णे व॑सन्ति" इति प्रामाण्येन अनुगृह्णन्तु।

(८) अनेन अष्टमवार रुद्रजपेन भीमाऽऽख्यः आदित्यात्मकः श्रीरुद्रः सुप्रसन्नो भूत्वा—

"भी॒षास्मा॒द्वात॑ः पवते। भी॒षोऽदे॑ति॒ सूर्य॑ः।
भीषास्मादग्नि॑श्चेन्द्र॒श्च। मृत्युर्धा॑वति पञ्च॑म इ॒ति॥
"यद्भयाद्वर्षते देवो भगणो भाति यद्भयात्।
यद्वनस्पतयो भीताः लताश्चौषधिभिः सह
स्वे स्वे कालेऽभिगृह्णन्ति पुष्पाणि च फलानि च॥

इत्यादि श्रुति स्मृति वचनात् सर्वनियन्ता स्वेमहिम्न स्थितः यं 'नेति नेति' वचनैः निगमाः अवोचन् सः अस्मासु क्षुत्-तृष्णे जरा-मृत्यू शोक-मोहौ इति षडूर्मिभ्यः रक्षां विदध्यात् इति प्रार्थयामहे। तत्फलसिध्यर्थं मन्त्रविदः भवन्तः आशिषः वर्षित्वा सम्यगनुगृह्णन्तु॥

(९) अनेन नवमवार रुद्रजपेन 'देवदेव' इति विश्रुतः आदित्यात्मकः श्रीरुद्रः सुप्रसन्नो वरदो भूत्वा—

"श्र॒द्धा दे॒वानधि॑वस्ते। श्र॒द्धा विश्व॑मि॒दं जग॑त्।
श्र॒द्धां काम॑स्य मा॒तर॑म्। ह॒विषा॑ वर्धयामसि॥"

In Public domain. Digitization Muthulakshmi Research Academy

"श्रद्धावान् लभते ज्ञानं तत्परः संयतेन्द्रियः।
ज्ञानं लब्ध्वा परां शान्ति मचिरेणाऽधिगच्छति॥

इत्यादि श्रुति स्मृति अनुशासनात् सः परमेश्वरः अस्मासु आध्यात्मिकी श्रद्धां दत्वा तत्पादारविन्दयोः अचञ्चल भक्ति द्वारा परमशान्तिं च दद्यात् इति भवन्तः अनुगृह्णन्तु॥

(१०) अनेन दशमवार रुद्रजपेन भवोद्भव इति पवित्रकीर्त्या भावितः आदित्यात्मकः श्रीरुद्रः सुप्रसन्नो वरदो भूत्वा—

"भवे भवे नाऽतिभवे भवस्व माम्। भवोद्भवाय नमः"
"मुखानि पञ्चोपनिषदस्तवेश यैस्त्रिंशदष्टोत्तरमन्त्रवर्गः।
यत्तच्छिवाख्यं परमार्थतत्त्वं देव स्वयंज्योतिरवस्थितिस्ते॥

इत्यादि उद्घोषित महिम्नः यस्य परं ज्योतिः अखिलानां लोकपालानां अवगम्यं न भवति, तस्य अनुग्रहेण भूतलप्रदेशस्य समुद्रप्लावनं, भूचलनं इत्यादि आधिदैविक आधिभौतिक उपाधिभिः संभाव्यमान दुरितानि विशेषतः भारतदेशे मा भूवन् इति पञ्चाक्षरं पावनमुञ्चरन्तः, पतिं पशूनां हृदि भावयन्तः भवन्तः सम्यगनुगृह्णन्तु॥

(११) अनेन एकादशवार रुद्रजपेन आदित्यात्मकः श्रीरुद्रः सुप्रसन्नो वरदो भूत्वा—

"यतो वा इमानि भूतानि जायन्ते।
येन जातानि जीवन्ति। यत्प्रयन्त्यभि संविशन्ति॥"
विश्वस्य यः स्थितिलयोद्भवहेतुराद्यो
योगेश्वरैरपि दुरत्यय योगमायः॥
"एको देवः सर्वभूतेषु गूढः सर्वव्यापी सर्वभूतान्तरात्मा"
"यो ब्रह्माणं विदधाति पूर्वं यो वै वेदांश्च प्रहिणोति तस्मै॥"

In Public domain. Digitization Muthulakshmi Research Academy

इत्यादिभिः यं सर्वज्ञं सर्वशक्तिं सर्वेश्वरं सर्वनियन्तारं सर्वोपास्यं सर्वकर्मफलप्रदातारं समस्तकल्याणगुणनिलयं सच्चिदानन्दं भगवन्तं श्रुतयः प्रतिपादयन्ति सः सर्वेषां आस्तिक-महाजनानां तापत्रय निवृत्तिप्रदः, अपमृत्यु निवृत्तिप्रदः, अकाल-मृत्यु निवृत्तिप्रदः, सकलरोग पीडा निवृत्तिप्रदः, दीर्घायुष्य सिद्धिप्रदः, समस्तमङ्गलाऽवाप्तिप्रदश्च भूयादिति भवन्तः—

''विप्रा मन्त्रविदो युक्तास्तैर्याःप्रोक्तास्तदाशिषः।
ता निष्फला भविष्यन्ति न कदाचिदपि स्फुटं॥''
इति प्रामाण्येन सम्यगनुगृह्णन्तु॥

ओं शान्तिः शान्तिः शान्तिः॥

॥ श्री रुद्र होमः ॥

॥ रुद्रैकादशिन्याम् ॥

द्वादश ऋत्विजः एक वारं श्री रुद्र हवनं कुर्युः। श्री रुद्र प्रथमर्चा एकाहुतिः अन्त्यया ऋचा एकाहुतिः चमक प्रश्नस्य एकादशानुवाकैः प्रत्यनुवाकं इति एकादशाहुतयः आचार्येण कर्तव्याः। अनन्तरं वसोर्द्धारा। सामगानं॥

महारुद्रेः—

द्वादश ऋत्विजः दशवारं श्री रुद्रहोमं कुर्युः अन्त्ये एकादश वारे त्रयोदश ऋत्विजः श्रीरुद्रहोमं कृत्वा, द्वादश ऋत्विजः प्रत्यनुवाकंएकादश चमकानुवाकैः हवनं कृत्वा, श्रीरुद्र आद्यन्त ऋग्भ्यां आचार्य एव हुत्वा, वसोर्द्धारां जुहुयात्॥

अतिरुद्रे—

द्वादश ऋत्विजः एकशतोत्तर द्वाविंशति आवृत्तीः कृत्वा आचार्यः श्रीरुद्रस्य आद्यऋचा अन्त्य ऋचा हवनं कृत्वा वसोर्धारां जुहुयात्॥

In Public domain. Digitization Muthulakshmi Research Academy

आपस्तंब अग्निमुख प्रयोगः

उल्लिख्य। अवोक्ष्य। भू र्भुवस्सुवरोमिति अग्निं प्रतिष्ठाप्य। अग्निमिध्वा। अग्निं प्रज्वाल्य। प्राक्तोयं निधाय। परिस्तीर्य, पुरस्तात्, दक्षिणतः, पश्चात्, उत्तरतः। दक्षिणानुत्तरान् उत्तरानऽधरान्। पात्रोत्तरासनं। प्रणीतोत्तरासनं। पश्चात्पात्र सादनं। आयामतः परीमाणं प्रोक्षणी संस्कारः पात्रपोक्ष इति। समौ अप्रच्छिन्नाग्रौ दर्भौ प्रादेशमात्रौ पवित्रे कुरुते। स पवित्रेण पाणिना पात्राणि संस्पृश्य। दर्वीं, आज्यस्थालीं, प्रोक्षणीं प्रणीतां, इतरदर्वीं इध्मं च सादयित्वा। प्रोक्षणी पात्रमादाय, अक्षतैस्सह, उदकं पूरयित्वा, त्रिः उत्पूय, उत्तानानि पात्राणि कृत्वा, त्रिः सर्वाभिरद्भिः प्रोक्ष्य, प्रोक्षणीपात्रं दक्षिणतः निधाय, प्रणीता पात्रमादाय, अक्षतैः सह, अप आसिच्य, त्रिः उत्पूय, समं प्राणैर्हृत्वा, उत्तरेणाग्निं दर्भेषु सादयित्वा, दर्भैः प्रच्छाद्य। वरुणाय नमः सकलाराधनैः स्वर्चितम् (उत्तरेणाग्निं कुंभे आपोवा इत्यादि जपित्वा, वरुणं आवाह्य, प्रधान देवताश्च आवाह्य षोडशोपचारेण संपूज्य)। अग्नेः दक्षिणतः ब्रह्मवरणं। अस्मिन्...... होम कर्मणि ब्रह्माणं त्वां वृणे। ब्रह्मणे नमः सकलाराधनैः स्वर्चितं। पवित्रान्तर्हितायां आज्य स्थाल्यां आज्यं निरुह्य। उदीचोङ्गारान् निरुह्य। तेषु आज्यं अधिश्रित्य। ज्वलता तृणेनावद्योत्य, द्वे दर्भाग्रे प्रच्छिद्य प्रक्षाळ्य प्रत्यस्य। त्रिः पर्यग्नि कृत्वा। उदगुद्वास्य। अङ्गारान् प्रत्यूह्य। उदगग्राभ्यां पवित्राभ्यां पुनराहारं आज्यं त्रिः उत्पूय। पवित्रग्रन्थिं विस्रस्य, (अपउपस्पृश्य), प्रागग्रामग्नौ प्रहरति। येन जुहोति, तदग्नौ प्रतितप्य, दर्भैः संमृज्य, पुनः प्रति तप्य, प्रोक्ष्य, निधाय, दर्भान् अद्भिः संस्पृश्य अग्नौ प्रहरति। अथ परिधीन् परिदधाति। स्थविष्ठो मध्यमः। अणीयान्द्राघीयान् दक्षिणार्ध्यः। अणिष्ठो ह्रसिष्ठ उत्तरार्ध्यः। द्वे आघार समिधौ, मध्यमं परिधिं,

In Public domain. Digitization Muthulakshmi Research Academy

हस्तेनोपस्पृश्य, दक्षिणमुत्तर मादधाति, ऊर्ध्वे समिधा-वादधाति। अथाग्निं परिषिञ्चति। अदितेऽनुमन्यस्व इति दक्षिणतः प्राचीनं। अनुमऽतेनु मन्यस्वेति पश्चादुदीचीनं। सरस्वतेऽनु मन्यस्वेति उत्तरतः प्राचीनं। देव सवितः प्रसुवेति समन्तं परिषिच्य। इध्ममाज्येन अभ्यज्य। ओमस्मिन्...... होमकर्मणि ब्रह्मन् इध्ममाधास्ये॥ ब्रह्मा-ओमाधत्स्व॥ ब्रह्मार्पणं॥ प्रजापतिं मनसा ध्यायन्, आधारावाधारयति। इतर दर्व्या जुहोति। वायव्या दाग्नेयान्तं। प्रजापतय इदं न मम॥ प्रधान दर्व्या जुहोति। निर्ऋत्या ईशानान्तं। इन्द्रायेदं न मम॥ उत्तरार्ध पूर्वार्धे अग्नये स्वाहा। अग्नय इदं न मम॥ दक्षिणार्धपूर्वार्धे सोमाय स्वाहा। सोमायेदं न मम॥ समं पूर्वेण मध्ये अग्नये स्वाहा। अग्नय इदं न मम॥ आरंभ प्रभृति एतत्क्षणपर्यन्तं मध्ये संभावित समस्त दोषप्रायश्चित्तार्थं सर्वप्रायश्चित्त होमं होष्यामि। ओं भूर्भुवस्सुवस्वाहा॥ प्रजापतय इदं न मम॥

श्रीरुद्रविधानेन अग्नौ श्री आदित्यात्मक महादेवं आवाह्य, षोडशोपचारैः संपूज्य चरुं, श्रपयित्वा, प्रोक्ष्य, अभिघार्य, प्राचीनमुदीचीनं लोद्वास्य प्रतिष्ठित मभिघार्य, अवदान धर्मेणावदाय

"असौयस्ताम्रो अरुण उत बभ्रुस्सुमङ्गलः। येचेमाꣳ रुद्रा अभितो दिक्षु श्रितास्सहस्रशोवैषाꣳहेड ईमहे॥

असौ यो वसर्पति नीलग्रीवो विलोहितः।

उतैनं गोपा अदृशन्नदृशन्नुद हार्यः॥

उतैनं विश्वा भूतानि सदृष्टो मृडयाति नस्स्वाहा॥"

इति पुरोनुवाक्या मनूच्ययाज्यया जुहुयात्। आदित्यात्मक श्री रुद्रायेदं न मम॥ स्विष्टकृतमवदाय अन्तः परिधि साद-

In Public domain. Digitization Muthulakshmi Research Academy

यित्वा॥ श्री रुद्र होमं अनुषङ्गेण यथाविधि (त्रेधा/षोढा/ षोडशधा/अष्टाचत्वारिंशद्धा/ एकोनसप्तत्यधिकशतधा विभागः) हुत्वा॥

I. अथ त्रेधा विभागः

(१) "नमस्ते रुद्र मन्यवे" इत्यारभ्य नमः क्षतृभ्यस्संग्रहीतृभ्यश्च वो नमस्तक्षभ्य स्स्वाहा॥

(२) रथ कारेभ्यश्च वो नम इत्यारभ्य नमस्तीक्ष्णे षवे चायुधिने च नम स्वायुधाय च स्वाहा॥

(३) सुधन्वने च नम इत्यारभ्य तं वो जंभे दधामि स्वाहा॥

II. अथान्य प्रकारः त्रेधा विभाग पक्षः

(१) नमस्ते रुद्र मन्यवे इत्यारभ्य श्वभ्य श्वपतिभ्यश्च वो नम स्स्वाहा इत्यन्तं अनुवाक चतुष्टयं एकाहुतिः॥

(२) नमो भवाय च इत्यारभ्य नमस्सिकत्याय च प्रवाह्याय च स्वाहा इति मध्य अनुवाक चतुष्टयं द्वितीयाहुतिः॥

(३) नम इरिण्याय च इत्यारभ्य तं वो जंभे दधामि स्वाहा इति अन्त्य अनुवाक त्रयस्य एकाहुतिः इति॥

2. षोढा विभागः (६)

षोढा विभागे तु उपर्युक्त आहुति त्रयेण, अन्त्य "नमो रुद्रेभ्यो ये पृथिव्यां" इति मंत्रस्य त्रिधा अनुषंगेन षोढा विभागः संपद्यते॥

3. षोडशधा विभागः (१६)

(१) "नमस्ते रुद्र मन्यव" इत्यारभ्य "नमस्तक्षभ्यस्स्वाहा" इत्यन्तं एकाहुतिः॥

In Public domain. Digitization Muthulakshmi Research Academy

(२) रथकारेभ्य इत्युपक्रम्य स्वायुधाय च स्वाहा इति द्वितीयाहुतिः ॥

(३) सुधन्वने चेत्युपक्रम्य पराचीना मुखाकृधि स्वाहा इति तृतीयाहुतिः ॥

(४) सहस्राणि सहस्रशो ये इत्यारभ्य य एतावन्तश्च भूयाꣳ सश्च इत्यन्ता दशर्चः अनुषंगेन दशाहुतयः ॥

(५) नमो रुद्रेभ्य इति मन्त्रस्य त्रिधा अनुषंगेन त्रिधा होमः ॥

4. <u>अथ अष्टाचत्वारिंशद्धा विभागः</u> (४८)

(१) प्रथमानुवाके पंचदश मन्त्राः ॥

(२) ततः द्वितीयानुवाक मारभ्य नवमानुवाक पर्यन्तं एकैकानुवाकस्य एकैक होमः इति अष्ट होमाः ॥

(३) द्रापे अन्धसस्पते इति द्वादश मन्त्राः ॥

(४) सहस्राणि सहस्रशो इत्यस्य त्रयोदशा हुतयः ॥ इति ॥

5. <u>एकोन सप्तत्यधिक शतधा विभागः</u> (१६९)

(१) प्रथमानुवाके पंचदश मंत्राः ॥

(२) नमो हिरण्य बाहवे इति त्रयोदश होमाः ॥

(३) नम स्सहमानाय इति सप्तदश होमाः ॥

(४) नम आव्याधिनीभ्यः इति सप्तदश होमाः ॥

(५) नमो भवाय च इति पंचदश मन्त्राः ॥

(६) नमो ज्येष्ठाय च इति पंचदश मन्त्राः ॥

(७) नमो दुन्दुभ्याय च इति षोडश मन्त्राः ॥

(८) नम स्सोमाय च इति सप्तदश मन्त्राः ॥

(९) नम इरिण्याय च इति एकोनविंशति मन्त्राः ॥

(१०) द्रापे अन्धसस्पते इति द्वादश मन्त्राः ॥

(११) सहस्राणि सहस्रशो ये इति त्रयोदश होमाः ॥

मिलित्वा १६९ होमाः ॥

In Public domain. Digitization Muthulakshmi Research Academy

॥ स्विष्टकृतहोमः ॥

“हव्यवाहमभिमातिषाहम्। रक्षोहणं पृतनासु जिष्णुम्। ज्योतिष्मन्तं दीद्यतं पुरन्धिम्। अग्निꣳ स्विष्टकृत माहुवेमहोम्”॥ स्विष्टकृत माहुवेमोम्।। स्विष्टमग्ने अभितत्पृणाहि। विश्वादेव पृतना अभिष्य। उरुन्नः पन्था प्रदिशन्विभाहि। ज्योतिष्मद्धेह्यजरं न आयुस्स्वाहा॥ अग्नये स्विष्टकृत इदं न मम॥

॥ वसोर्धारा विधानम्॥

(Recited Prior to Vasordhara)

॥ अग्नि ऋषिः॥ (तै. सं. ५.४.८)

वसोर्धारां जुहोति वसोर्मे धाराऽसदिति वा एषा हूयते घृतस्य वा एनमेषा धाराऽमुष्मिं ल्लोके पिन्व मानोप तिष्ठत, आज्येन जुहोति तेजो वा आज्यं तेजो वसोर्धारा तेज सैवास्मै तेजोऽव रुन्धे, ऽथो कामा वै वसोर्धारा कामा नेवा वरुन्धे, यं कामयेत प्राणा नस्या न्नाद्यं विछिन्द्या मिति विग्राहं तस्य जुहुयात् प्राणा नेवास्यान्नाद्यं विच्छिनत्ति, यं कामयेत प्राणानस्या नाद्य ꣳ सं तनुयामिति संततां तस्य जुहुयात् प्राणानेवास्यान्नाद्य ꣳ सं तनोति, द्वादश द्वादशानि जुहोति द्वादश मासाः संवत्सरः सं वत्सरे णैवास्मा अन्न मव रुन्धे, ऽन्नं च मेऽ क्षुच्च म इत्याहि तद्वा अन्नस्य रूप ꣳ रूपेणैवान्न मव रुन्धे, ऽग्निश्च म आपश्च म इत्याहैषा वा अन्नस्य योनिः सयो न्येवान्न मव रुन्धे, ऽर्धेन्द्राणि जुहोति देवता एवाव रुन्धे यत् सर्वेषा मर्ध मिन्द्रः प्रति तस्मा दिन्द्रो देवतानां

In Public domain. Digitization Muthulakshmi Research Academy

भूयिष्ठ भाक्तम इन्द्र मुत्तर माहेन्द्रिय मेवास्मि न्नुपरिष्टाद् दधाति, यज्ञा युधानि जुहोति यज्ञो वै यज्ञायुधानि यज्ञमेवाव रुन्धेऽथो एतद्वै यज्ञस्य रूप ँ रूपेणैव यज्ञमवरुन्धे, ऽ व भृथश्च मे स्वगाकारश्च म इत्याह स्वगाकृत्या, अग्निश्च मे घर्मश्च म इत्याहैतद्वै ब्रह्मवर्चसस्य रूप ँ रूपेणैव ब्रह्मवर्चस मवरुन्ध, ऋक् च मे साम च म इत्याहै तद्वै छन्दसा ँ रूप ँ रूपेणैव छन्दा ँ स्यव रुन्धे, गर्भाश्च मे वथ्साश्च म इत्याहै तद्वै पशूना ँ रूप ँ रूपेणैव पशूनव रुन्धे, कल्पाञ्जुहोत्य क्लृप्तस्य क्लृप्त्यै, युग्म दयुजे जुहोति मिथुनत्वायो, त्तरावती भवतो ऽभिक्रान्त्या, एकाचमे तिस्रश्च म इत्याहदेव छन्दसं वा एकाच तिस्रश्च मनुष्य छन्दसं चतस्त्रश्चाष्टौ च देवछन्दसं चैव मनुष्य छन्दसं चावरुन्ध, आ त्रयस्त्रि ँ शतो जुहोति त्रयस्त्रि ँ शद्वै देवता देवता एवा व रुन्ध आऽष्टा चत्वारि ँ शतो जुहोत्यष्टा चत्वारि ँ शदक्षरा जगती जागताः पशवो जगत्यै वास्मै पशूनव रुन्धे, वाजश्च प्रसवश्चेति द्वादशं जुहोति द्वादश मासाः संवत्सरः संवत्सर एव प्रति तिष्ठति॥

॥ जयादि होमः ॥

ततो जयादि होमः॥ एतत्कर्म समृध्यर्थं जयादि होमं करिष्ये॥

१. चित्तं च स्वाहा—चित्तायेदं न मम।

In Public domain. Digitization Muthulakshmi Research Academy

२. चित्तिश्च स्वाहा—चित्याइदं न मम।

३. आकूतं च स्वाहा—आकूतायेदं न मम।

४. आकूतिश्च स्वाहा—आकूत्याइदं न मम।

५. विज्ञातञ्च स्वाहा—विज्ञातायेदं न मम।

६. विज्ञानञ्च स्वाहा—विज्ञानायेदं न मम।

७. मनश्च स्वाहा—मनस इदं न मम।

८. शक्वरीश्च स्वाहा—शक्वरीभ्य इदं न ममं।

९. दर्शश्च स्वाहा—दर्शायेदं न मम।

१०. पूर्णमासश्च स्वाहा—पूर्णमासा येदं न मम।

११. बृहच्च स्वाहा—बृहत इदं न मम।

१२. रथन्तरञ्च स्वाहा—रथन्तरायेदं न मम।

१३. प्रजापति र्जयानिन्द्राय वृष्णे प्रायच्छदुग्रः पृतनाज्यैषु तस्मै विशः समनमन्त सर्वास्स उग्रः सहिहव्यो बभूव स्वाहा॥ प्रजापतय इदं न मम।

१४. अग्निर्भूताना मधिपतिः समावत्वस्मिन्ब्रह्मन् न्नस्मिन्क्षत्रे ऽस्यामाशिष्यस्यां पुरोधाया मस्मिन्कर्म न्नस्यां देवहूत्याँ स्वाहा। अग्नय इदं न मम।

१५. इन्द्रो ज्येष्ठाना मधिपतिः समावत्वस्मिन्ब्रह्म न्नस्मिन्क्षत्रे ऽस्यामाशिष्यस्यां पुरोधाया मस्मिन्कर्म न्नस्यां देवहूत्याँ स्वाहा। इन्द्रायेदं न मम।

१६. यमः पृथिव्याऽधिपति स्समावत्वस्मिन्ब्रह्म न्नस्मिन्क्षत्रे ऽस्यामाशिष्यस्यां पुरोधाया मस्मिन्कर्म न्नस्यां देवहूत्याँ स्वाहा। यमायेदं न मम।

In Public domain. Digitization Muthulakshmi Research Academy

१७. वायुरन्तरिक्षस्याधिपति स्समावत्वस्मिन्ब्रह्मन्नस्मिन्क्षत्रेऽस्यामाशिष्यस्यां पुरोधाया मस्मिन्कर्मन्नस्यां देवहूत्याꣳ स्वाहा। वायव इदं न मम।

१८. सूर्योऽदिवोऽधिपति स्समावत्वस्मिन्ब्रह्मन्नस्मिन्क्षत्रेऽस्यामाशिष्यस्यां पुरोधाया मस्मिन्कर्मन्नस्यां देवहूत्याꣳ स्वाहा। सूर्यायेदं न मम।

१९. चन्द्रमा नक्षत्राणामधिपतिः समावत्वस्मिन्ब्रह्म न्नस्मिन्क्षत्रे-ऽस्यामाशिष्यस्यां पुरोधाया मस्मिन्कर्मन्नस्यां देवहूत्याꣳ-स्वाहा। चन्द्रमस इदं न मम।

२०. बृहस्पति र्ब्रह्मणोधिपतिः समावत्वस्मिन्ब्रह्मन्नस्मिन्क्षत्रेऽस्यामाशिष्यस्यां पुरोधाया मस्मिन्कर्मन्नस्यां देवहूत्याꣳ स्वाहा। बृहस्पतयइदं न मम।

२१. मित्रस्सत्यानामधिपतिः समावत्वस्मिन्ब्रह्मन्नस्मिन्क्षत्रेऽस्यामाशिष्यस्यां पुरोधाया मस्मिन्कर्मन्नस्यां देवहूत्याꣳ स्वाहा। मित्रायेदं न मम।

२२. वरुणोऽपामधिपतिः समावत्वस्मिन्ब्रह्मन्नस्मिन्क्षत्रेऽ स्यामाशिष्यस्यां पुरोधाया मस्मिन्कर्मन्नस्यां देवहूत्याꣳ स्वाहा। वरुणायेदं न मम।

२३. समुद्रस्स्रोत्याना मधिपतिस्समावत्वस्मिन्ब्रह्म न्नस्मिन्क्षत्रेऽस्यामाशिष्यस्यां पुरोधाया मस्मिन्कर्मन्नस्यां देवहूत्याꣳ स्वाहा। समुद्रायेदं न मम।

२४. अन्नꣳ साम्राज्याना मधिपतिः तन्मावत्वस्मिन्ब्रह्म न्नस्मिन्क्षत्रे ऽस्यामाशिष्यस्यां पुरोधाया मस्मिन्कर्मन्नस्यां

In Public domain. Digitization Muthulakshmi Research Academy

देवहूत्याꣳ स्वाहा। अन्नायेदं न मम।

२५. सोम ओषधीनामधिपतिस्समावत्वस्मिन्ब्रह्म न्नस्मिन्क्षत्रेऽस्यामाशिष्य स्यां पुरोधाया मस्मिन्कर्म न्नस्यां देवहू त्याꣳ स्वाहा। सोमायेदं न मम।

२६. सविता प्रसवानामधिपति स्समावत्वस्मिन्ब्रह्म न्नस्मिन्क्षत्रे-ऽस्यामाशिष्यस्यां पुरोधाया मस्मिन्कर्म न्नस्यां देवहूत्याꣳ स्वाहा। सवित्रइदं न मम।

२७. रुद्रः पशूनामधिपति स्समावत्वस्मिन्ब्रह्म न्नस्मिन्क्षत्रेऽस्यामाशिष्यस्यां पुरोधाया मस्मिन्कर्म न्नस्यां देवहूत्याꣳ स्वाहा। रुद्रायेदं न मम। (अपउपस्पृश्य।)

२८. त्वष्टा रूपाणा मधिपति स्समावत्वस्मिन्ब्रह्म न्नस्मिन्क्षत्रेऽस्यामाशिष्यस्यां पुरोधायामस्मिन्कर्म न्नस्यां देवहूत्याꣳ स्वाहा। त्वष्ट्र इदं न मम।

२९. विष्णुः पर्वताना मधिपति स्समावत्वस्मिन्ब्रह्म न्नस्मिन्क्षत्रेऽस्यामाशिष्यस्यां पुरोधाया मस्मिन्कर्म न्नस्यां देवहूत्या ꣳ स्वाहा। विष्णव इदं न मम।

३०. मरुतो गणानामधिपतयस्तेमावन्त्वस्मिन् ब्रह्म न्नस्मिन्क्षत्रेऽस्यामाशिष्यस्यां पुरोधाया मस्मिन्कर्म न्नस्यां देवहूत्याꣳ-स्वाहा। मरुद्भ्य इदं न मम।

३१. पितरः पितामहाः परेऽवरे ततास्ततामहा इहमावत। अस्मिन्ब्रह्मन्नस्मिन्क्षत्रेऽस्यामाशिष्यस्यां पुरोधाया मस्मिन्कर्म न्नस्यां देवहूत्याꣳस्वाहा। मन्त्रोक्त देवताभ्य इदं न मम। (अपउपस्पृश्य।)

In Public domain. Digitization Muthulakshmi Research Academy

३२. ऋताषाडृतधामाऽग्निर्गन्धर्वस्तस्यौषधयोऽप्सरस ऊर्जो नाम स इदं ब्रह्म क्षत्रं पातु ता इदं ब्रह्मक्षत्रं पान्तु तस्मै स्वाहा। अग्नये गन्धर्वायेदं न मम॥ ताभ्य स्वाहा। ओषधीभ्योऽप्सरोभ्य इदं न मम॥

३३. संहितो विश्वसामा सूर्यो गन्धर्वस्तस्य मरीचयोऽप्सरस आयुवो नाम सइदं ब्रह्मक्षत्रं पातु ता इदं ब्रह्मक्षत्रं पान्तु तस्मै स्वाहा। सूर्याय गन्धर्वायेदं न मम॥ ताभ्यः स्वाहा। मरीचिभ्योऽप्सरोभ्यइदं न मम॥

३४. सुषुम्न स्सूर्य रश्मिश्चन्द्रमा गन्धर्वस्तस्य नक्षत्राण्यऽप्सरसो बेकुरयो नाम स इदं ब्रह्मक्षत्रं पातु ता इदं ब्रह्मक्षत्रं पान्तु तस्मै स्वाहा। चन्द्रमसे गन्धर्वायेदं न मम॥ ताभ्यः स्वाहा। नक्षत्रेभ्योऽप्सरोभ्य इदं न मम॥

३५. भुज्युस्सुपर्णो यज्ञो गन्धर्वस्तस्य दक्षिणा अप्सरसस्तवा नाम स इदं ब्रह्मक्षत्रं पातु ता इदं ब्रह्मक्षत्रं पान्तु तस्मै स्वाहा। यज्ञाय गन्धर्वायेदं न मम॥ ताभ्यः स्वाहा। दक्षिणाभ्योऽप्सरोभ्य इदं न मम॥

३६. प्रजापतिर्विश्वकर्मा मनो गन्धर्वस्तस्यर्क्सामान्यऽप्सरसो वह्नयो नाम स इदं ब्रह्मक्षत्रं पातु ता इदं ब्रह्मक्षत्रं पान्तु तस्मै स्वाहा। मनसे गन्धर्वायेदं न मम॥ ताभ्यः स्वाहा। ऋक्सामेभ्योऽप्सरोभ्य इदं न मम॥

३७. इषिरो विश्वव्यचा वातोगन्धर्वस्तस्यापोऽप्सरसो मुदानाम स इदं ब्रह्मक्षत्रं पातु ता इदं ब्रह्मक्षत्रं पान्तु तस्मै स्वाहा। वाताय

In Public domain. Digitization Muthulakshmi Research Academy

गन्धर्वायेदं न मम॥ ताभ्यः स्वाहा। अद्भ्योऽप्सरोभ्य इदं न मम।

३८. भुवनस्यपते यस्य त उपरि गृहा इह च। सनो रास्वा ज्यानिꣳ रायस्पोषꣳ सुवीर्यꣳ संवत्सरीणाꣳ स्वस्तिꣳ स्वाहा। भुवनस्य पत्य इदं न मम।

३९. परमेष्ठ्यधिपति मृत्युर्गन्धर्वस्तस्य विश्वमप्सरसो भुवो नाम स इदं ब्रह्मक्षत्रं पातु ता इदं ब्रह्मक्षत्रं पान्तु तस्मै स्वाहा। मृत्यवे गन्धर्वायेदं न मम॥ ताभ्य स्स्वाहा। विश्वस्मा-ऽप्सरोभ्य इदं न मम।

४०. सुक्षितिस्सुभूति भद्रकृत्सुवर्वान्पर्जन्यो गन्धर्वस्तस्य विद्युतोऽप्सरसो रुचो नाम स इदं ब्रह्मक्षत्रं पातु ता इदं ब्रह्मक्षत्रं पान्तु तस्मै स्वाहा। पर्जन्याय गन्धर्वायेदं न मम॥ ताभ्य स्स्वाहा। विद्युद्भ्योऽप्सरोभ्य इदं न मम।

४१. दूरे हेति रमृडयो मृत्युर्गन्धर्वस्तस्य प्रजा अप्सरसो भीरुवो नाम स इदं ब्रह्मक्षत्रं पातु ता इदं ब्रह्मक्षत्रं पान्तु तस्मै स्वाहा। मृत्यवे गन्धर्वायेदं न मम॥ ताभ्य स्स्वाहा। प्रजाभ्योऽप्सरोभ्य इदं न मम।

४२. चारुः कृपण काशी कामो गन्धर्वस्तस्या धयोऽप्सरसः शोचयन्तीर्नाम स इदं ब्रह्मक्षत्रं पातु ता इदं ब्रह्मक्षत्रं पान्तु तस्मै स्वाहा। कामाय गन्धर्वायेदं न मम॥ ताभ्यः स्वाहा। आधिभ्योऽप्सरोभ्य इदं न मम।

४३. सनो भुवनस्य पते यस्य त उपरि गृहा इह च। उरु ब्रह्मणेस्मै

In Public domain. Digitization Muthulakshmi Research Academy

क्षत्राय महि शर्म यच्छ स्वाहा॥ भुवनस्य पत्ये ब्रह्मण इदं न मम।

४४. प्रजापते नत्वदे तान्यन्यो विश्वा जातानि परिता बभूव। यत्कामास्ते जुहुमस्तन्नो अस्तु वयँस्याम पतयो रयीणाँ स्वाहा॥ प्रजापतय इदं न मम।

४५. भू स्स्वाहा। अग्नय इदं न मम॥ भुवस्स्वाहा। वायव इदं न मम॥ सुवः स्वाहा। सूर्यायेदं न मम॥

यदस्य कर्मणोऽत्यरीरिचं यद्वा न्यून मिहाकरम्। अग्निष्टत् स्विष्टकृद्विद्वान्सर्वँस्विष्टँसुहुतं करोतु स्वाहा। अग्नये स्विष्टकृत इदं न मम॥

परिध्यञ्जनं। लेपकार्यं॥ प्रधान दर्वीं दक्षिणतः। इतरदर्वीं मध्ये। आज्यस्थाली मुत्तरतः॥ पात्र प्रयुक्तं तृणमक्त बर्हिः। अग्रं मध्यं मूलं एवं त्रिः। एकं दर्भं प्रज्ञातं निधाय। अग्नौ प्रहरति। (अपउपस्पृश्य)। तृण प्रहरः। निर्देशनञ्च। अग्नि मभिमन्त्रणञ्च। भूमौ निमार्ष्टि। परिधि प्रहरः। इतरौ प्रहरन्। सँस्त्रावं जुहोति- वसुभ्यो रुद्रेभ्य आदित्येभ्यो विश्वेभ्यो देवेभ्यः सँस्त्राव भागेभ्य इदं न मम।

(व्रतेषु सुवनेषुच तथास्वाध्ययने मखे। परिधि प्रहरणं कुर्यात् लेपकार्यं न विद्यते॥)

(विवाहोपनयन समावर्तन सीमन्त चौळ गोदान प्रायश्चित्तेषु शम्याअपोह्य॥)

अस्मिन् कर्मणि अविज्ञात प्रायश्चित्तानि करिष्ये। अनाज्ञातं यदाज्ञातम्। यज्ञस्य क्रियते मिथु। अग्ने तदस्य कल्पय। त्वँहि वेत्थयथातथँ स्वाहा॥ अग्नय इदं न मम॥ पुरुष संमितो यज्ञः। यज्ञः पुरुष संमितः। अग्ने तदस्य कल्पय। त्वँहि वेत्थयथा तथँ

In Public domain. Digitization Muthulakshmi Research Academy

स्वाहा॥ अग्नय इदं न मम॥ यत्पाकत्रा मनसा दीन दक्षान। यज्ञस्य मन्वते मर्तासः। अग्निष्ट द्धोता क्रतुविद्विजानन्। यजिष्ठो देवाः ऋतुशो यजाति स्वाहा। अग्नय इदं न मम॥ भू स्स्वाहा। अग्नय इदं। भुवस्स्वाहा। वायव इदं न मम। सुवस्स्वाहा। सूर्यायेदं न मम॥ ओं भूर्भुवस्सुव स्स्वाहा। प्रजापतय इदं न मम॥ अस्मिन्...... होम कर्मणि मध्ये संभावित मन्त्र-लोप तन्त्र-लोप क्रिया-लोप आज्य-लोप पद-लोप स्वर-लोप न्यूनातिरिक्त समस्त विस्मृत विधि विपर्यास विद्यापराध प्रायश्चित्तार्थं सर्वप्रायश्चित्त होमं होष्यामि। ओं भूर्भुवस्सुवस्स्वाहा। प्रजापतय इदं न मम॥ श्रीविष्णवे स्वाहा। विष्णवे परमात्मन इदं न मम॥ नमो रुद्राय पशुपतये स्वाहा। रुद्राय पशुपतय इदं न मम॥ (अपउपस्पृश्य।)

॥ पूर्णाहुतिः ॥

पूर्णाहुतिमुत्तमां जुहोति। सर्वं वैपूर्णाहुतिः। सर्वमेवाप्नोति। अथो इयं वै पूर्णाहुतिः। अस्यामेव प्रति तिष्ठति॥

त्रया देवा एकादश। त्रयस्त्रिंशास्सुराधसः। बृहस्पति पुरोहिताः। देवस्य सवितुस्सवे। देवा देवै रवन्तु मा। प्रथमा द्वितीयैः। द्वितीयास्तृतीयैः। तृतीयास्सत्येन। सत्यं यज्ञेन। यज्ञो यजुर्भिः। यजूंषि सामभिः। सामान्यृग्भिः। ऋचौ याज्याभिः। याज्या वषट्कारैः। वषट्कारा आहुतिभिः। आहुतयो मे कामान्समर्द्धयन्तु। पुनस्त्वाऽदित्या रुद्रा वसवस्समिन्धतांपुन ब्रह्माणो वसुनीथ यज्ञैः। घृतेनत्वं तनुवो वर्धयस्व सत्यास्सन्तु

In Public domain. Digitization Muthulakshmi Research Academy

यजमानस्य कामास्स्वाहा॥ सप्तते अग्ने समिधः सप्त जिह्वास्सप्त ऋषयस्सप्त धाम प्रियाणि। सप्तहोत्राः सप्त धात्वा यजन्ति सप्त योनीरापृणस्वा घृतेन स्वाहा। अग्नये सप्तवत इदं॥ आज्यपात्र मुत्तरतो निधाय। प्रायश्चित्तं प्राणायामः॥ परिषेचनं॥ अदितेऽन्वमꣳस्थाः। अनुमतेऽन्वमꣳस्थाः। सरस्वतेऽन्वमꣳस्थाः। देवसवितः प्रासावीः। वरुणाय नमः सकलाराधनैः स्वर्चितम्। प्रतिजलमिश्रं प्राच्यां दक्षिणायां प्रतीच्यां उदीच्यां ऊर्ध्वायां अधः। आत्मानं पत्नीं च प्रोक्ष्य॥ ब्रह्मन् वरं ते ददामि। ब्रह्मणे नमः। सकलाराधनैः स्वर्चितं॥

मानो महान्तमुत मानो अर्भकं मान उक्षन्तमुत मान उक्षितम्। मानो वधीः पितरं मोत मातरं प्रिया मानस्तनुवो रुद्र रीरिषः॥ इति अग्नेरुत्तरतः हुत शेषेण बलिं दद्यात्॥

स्वाहा॥ अग्नेरुपस्थानं करिष्ये॥ अग्नि सूक्तेन प्रदक्षिण नमस्कारान् कृत्वा।

अग्ने नय सुपथा राये अस्मान् विश्वानि देव वयुनानि विद्वान्। युयोध्यस्म ज्जुहुराण मेनो भूयिष्टान्ते नम उक्तिं विधेम। अग्नये नमः॥ (अग्निं आत्मन् उद्वासयामि। हृदये अञ्जलिं दद्यात्॥)

नमस्ते गार्हपत्याय नमस्ते दक्षिणाग्नये।
नम आहवनीयाय महावेद्यै नमो नमः॥
काण्डद्वयोप पाद्याय कर्म ब्रह्म स्वरूपिणे।
स्वर्गापवर्ग रूपाय यज्ञेशाय नमो नमः॥
यज्ञेशाच्युत गोविन्द माधवानन्त केशव।

In Public domain. Digitization Muthulakshmi Research Academy

कृष्ण विष्णो हृषीकेश वासुदेव नमोऽस्तु ते ॥
मन्त्रहीनं क्रियाहीनं भक्तिहीनं हुताशन ।
यद्धुतन्तु मयादेव परिपूर्णं तदस्तु ते ॥
प्रायश्चित्तानि अशेषाणि तपः कर्म आत्मकानि वै ।
यानितेषां अशेषाणां कृष्णानुस्मरणं परम् ॥
श्री कृष्ण कृष्ण कृष्ण ॥
अभिवादये......... ॥ (नमस्कारः)

अथ यजमानः

(१) शंभो ब्रह्मशिरच्छेदिन् ब्रह्माण्डालय नायक ।
नम उग्र महा भाग प्रथमार्घ्यं गृहाण भोः ॥
महादेवादिभ्यो नमः । इदमर्घ्यं इदमर्घ्यं इदमर्घ्यं ।

(२) वेदान्तागम सिद्धान्त यज्ञेश परमेश्वर ।
समस्त जगदाधार द्वितीयार्घ्यं गृहाण भोः ॥
महा देवादिभ्यो नमः । इदमर्घ्यं इदमर्घ्यं इदमर्घ्यं ।

(३) सर्व स्वातन्त्र्य साम्राज्य सर्व यज्ञ फल प्रद ।
दयालो भक्त संरक्ष तृतीयार्घ्यं गृहाण भोः ॥
महा देवादिभ्यो नमः । इदमर्घ्यं इदमर्घ्यं इदमर्घ्यं ।

(४) ब्रह्मादिभिः सुरैः सर्वैः स्तूयमान पदांबुज ।
अंबिका रमण स्वामिन् तुरीयार्घ्यं गृहाण भोः ॥
महा देवादिभ्यो नमः । इदमर्घ्यं इदमर्घ्यं इदमर्घ्यं ॥

इति अर्घ्यं दद्यात् ॥

हिरण्य गर्भ गर्भस्थं हेम बीजं विभावसोः । अनन्त पुण्य फलदं अतश्शान्तिं प्रयच्छमे ॥ इदं उत्तराङ्गतया विहित गो प्रतिनिधि नाळिकेरं दश दान पञ्चदान प्रत्याम्नायं यथा शक्ति हिरण्यं नाना गोत्रेभ्यः ब्राह्मणेभ्यः संप्रददे ॥ न मम ॥ कुंभे पुनः

In Public domain. Digitization Muthulakshmi Research Academy

पूजां कृत्वा, यथास्थानं प्रतिष्ठाप्य। देवस्यत्वादि मन्त्रेण प्रोक्ष्य, तीर्थं प्राश्य, ऋत्विक् आचार्यान् संपूज्य, आशीर्वादं कृत्वा, मङ्गल हारती॥ ओं तत्सत्॥

॥ दीपाराधना। मन्त्रपुष्पम्। प्रदक्षिण नमस्काराः॥

यानिकानि च पापानि जन्मान्तर कृतानि च।
तानितानि विनश्यन्ति प्रदक्षिण पदे पदे॥
शिवं शिवकरं शान्तं शिवात्मानं शिवोत्तमम्।
शिवमार्गप्रणेतारं प्रणतोऽस्मि सदाशिवम्॥
महादेवं महेशानं महेश्वरमुमापतिम्।
महासेन गुरुं वन्दे महाभय निवारणम्॥
मृत्युञ्जयाय रुद्राय नीलकण्ठाय शम्भवे।
अमृतेशाय शर्वाय महादेवाय ते नमः॥
नमश्शिवाभ्यां नवयौवनाभ्यां, परस्पराश्लिष्ट वपुर्धराभ्याम्।
नगेन्द्रकन्या वृषकेतनाभ्यां, नमो नमश्शङ्करपार्वतीभ्याम्॥
अन्यथा शरणं नास्ति त्वमेव शरणं मम।
तस्मात्कारुण्य भावेन रक्षरक्ष महेश्वर॥
अनायासेन मरणं वि ना दैन्येन जीवनम्।
देहि मे कृपया शम्भो त्वयि भक्तिम चञ्चलाम्॥
करचरणकृतं वाक्कायजं कर्मजं वा
श्रवणनयनजं वा मानसं वापराधं
विहितमविहितं वा सर्व मे तत्क्षमस्व
शिव शिव करुणाब्धे श्रीमहादेव शम्भो॥
आदित्यात्मक श्रीरुद्राय नमः।
अनन्तकोटि प्रदक्षिण नमस्कारान् समर्पयामि॥

In Public domain. Digitization Muthulakshmi Research Academy

अपराध सहस्त्राणि क्रियन्तेऽहर्निशं मया।
दासोऽयमिति मां मत्वा क्षमस्व परमेश्वर॥
मन्त्रहीनं क्रियाहीनं भक्तिहीनं महेश्वर।
यत्पूजितं मया देव परिपूर्णं तदस्तु ते।
अनयापूजया आदित्यात्मकः श्रीरुद्रः प्रीयताम्॥

(उद्वासनम्)—परितेधन्वनो.... त्र्यम्बकं यजामहे...... गौरीमिमाय..... ॐ भूर्भुवस्सुवरोम्। अस्मात् कुम्भात् अस्याः प्रतिमायाः महादेवं शिवं.... यथास्थानं प्रतिष्ठापयामि।

(अस्मात् मण्डलात् सपरिवार आदित्यात्मक श्रीरुद्रं यथास्थानं प्रतिष्ठापयामि। शोभनार्थे क्षेमाय पुनरागमनाय च)

ततः कुम्भजलेन शिवलिंगस्य अभिषेकः। प्रोक्षणम्। तीर्थप्राशनम्। आशीर्वादः॥ आचार्यसम्भावना। ऋत्विक्-सम्भावना। ब्रह्मार्पणम्।]

॥ प्रोक्षण मन्त्रः ॥

देवस्यत्वा सवितुः प्रसवे। अश्विनो॑र्बाहुभ्याम्॑। पूष्णो हस्ता॑भ्याम्। अश्विनो भैषज्येन। तेजसे ब्रह्मवर्चसायाभिषिञ्चामि।। देवस्यत्वा सवितुः प्रसवे। अश्विनो॑र्बाहुभ्याम्॑। पूष्णो हस्ता॑भ्याम्। सरस्वत्यै भैषज्येन। वीर्या॑या न्नाद्यायाऽभिषिञ्चामि। देवस्यत्वा सवितुः प्रसवे। अश्विनो॑र्बाहुभ्याम्॑। पूष्णो हस्ता॑भ्याम्। इन्द्रस्येन्द्रियेण। श्रियै यशसे बलायाभिषिञ्चामि॥

देवस्यत्वा सवितुः प्रसवे॑ऽश्विनो॑र्बाहुभ्या॑ पूष्णो हस्ता॑भ्याꣳ सरस्वत्यै वाचो यन्तु र्यन्त्रेणाऽग्ने स्त्वा साम्रा॑ज्येना भिषिञ्चामीन्द्रस्यत्वा साम्रा॑ज्येनाऽभिषिञ्चामि बृहस्पते॑स्त्वा साम्रा॑ज्येनाऽभिषिञ्चामि।

In Public domain. Digitization Muthulakshmi Research Academy

आयुरा शाँस्ते। सुप्रजास्त्व मा शाँस्ते। सजातवनस्यामा शाँस्ते। उत्तरान्देव यज्या मा शाँस्ते। भूयो हविष्करण मा शाँस्ते। दिव्यन्धामा शाँस्ते। विश्वं प्रियमा शाँस्ते। यदनेन हविषाऽऽशाँस्ते। तदश्या त्तदृध्यात्। तदस्मै देवा रासन्ताम्।

द्रुपदा दिवेन्मुमु चानः। स्विन्नः स्नात्वी मला दिव। पूतं पवित्रेणे वाज्यम्। आपः शुन्धन्तु मैनसः। भूर्भुवस्सुवो, भूर्भुवस्सुवो, भूर्भुवस्सुवः॥

॥ श्री रुद्र क्रम पाठः ॥

गणानां त्वा। त्वा गणपतिम्। गणपतिꣳ हवामहे। गणपति मिति गण ★ पतिम्। हवामहे कविम्। कविङ्कवीनाम्। कवीना मुप मश्रवस्तमम्। उप मश्रवस्तम मित्युप मश्रवः ★ तमम्॥ ज्येष्ठराजं ब्रह्मणाम्। ज्येष्ठराज मिति ज्येष्ठ ★ राजम्। ब्रह्मणां ब्रह्मणः। ब्रह्मणस्पते। पत आ। आनः। नः श्रृण्वन्। श्रृण्वन्नू- तिभिः। ऊतिभि स्सीद। ऊतिभि रित्यूति ★ भिः। सीद सादनम्। सादन मिति सादनम्॥

(१) नमस्ते। ते रुद्र। रुद्रमन्यवे। मन्यव उतो। उतो ते। उतो इत्युतो। त इषवे। इषवे नमः। नम इति नमः॥ नमस्ते। ते अस्तु। अस्तु धन्वने। धन्वने बाहुभ्याम्। बाहुभ्या मुत। बाहुभ्या मिति बाहु ★ भ्याम्। उतते। ते नमः। नम इति नमः॥ या ते। त इषुः। इषु श्शिवतमा। शिवतमा शिवम्। शिवत मेति शिव ★ तमा। शिवं बभूव। बभूव ते। ते धनुः। धनुरिति धनुः॥ शिवा शरव्या। शरव्या या। या तव। तव तया। तया नः। नो रुद्र।

In Public domain. Digitization Muthulakshmi Research Academy

रुद्रमृडय। मृडयेति मृडय॥ याते। ते रुद्र। रुद्र शिवा। शिवा तनूः। तनूरघोरा। अघोरा पापकाशिनी। अपाप काशिनी त्यपाप ★ काशिनी॥ तयानः। न स्तनुवा। तनुवा शन्तमया। शन्तमया गिरिशन्त। शन्त मयेति शं ★ तमया। गिरिशन्ताभि। गिरि शन्तेति गिरि ★ शन्त। अभि चाकशीहि। चाकशीहीति चाकशीहि॥ या मिषुम्। इषुं गिरिशन्त। गिरि शन्त हस्ते। गिरिशन्तेति गिरि ★ शन्त। हस्ते बिभर्षि।१॥ बिभर्ष्यस्तवे। अस्तव इत्यस्तवे॥ शिवां गिरित्र। गिरित्र ताम्। गिरित्रेति गिरि ★ त्र। तां कुरु। कुरुमा। मा हिꣳसीः। हिꣳसीः पुरुषम्। पुरुषं जगत्। जगदिति जगत्॥ शिवेन वचसा। वचसा त्वा। त्वा गिरिश। गिरिशाच्छ। अच्छा वदामसि। वदामसीति वदामसि॥ यथा नः। न स्सर्वम्। सर्व मित्। इज्जगत्। जगद यक्ष्मम्। अयक्ष्मꣳसुमनाः। सुमना असत्। सुमना इति सु ★ मनाः। असदित्यसत्॥ अध्यवो चत्। अवोचदधिवक्ता। अधिवक्ता प्रथमः। अधिवक्ते त्यधि ★ वक्ता। प्रथमो दैव्यः। दैव्यो भिषक्। भिषगिति भिषक्॥ अहीꣳश्च। च सर्वान्। सर्वाञ्जं भयन्न्। जंभयन्त्सर्वाः। सर्वाश्च। च यातुधान्यः। यातुधान्य इति यातु ★ धान्यः॥ असौ यः। य स्ताम्रः। ताम्रो अरुणः। अरुण उत। उत बभ्रुः। बभ्रु स्सुमङ्गलः। सुमङ्गल इति सु ★ मङ्गलः॥ ये च। चे माम्। इमाꣳरुद्राः। रुद्रा अभितः। अभितो दिक्षु। दिक्षु श्रिताः॥२॥ श्रिता स्सहस्रशः। सहस्र शोव। सहस्रश इति सहस्र ★ शः। अवैषाम्। एषाꣳहेडः। हेड ईमहे। ईमह इती महे॥ असौ यः। यौवसर्पति। अव सर्पति

In Public domain. Digitization Muthulakshmi Research Academy

नीलग्रीवः। अव सर्पती त्यव ★ सर्पति। नीलग्रीवो विलोहितः। नीलग्रीव इति नील ★ ग्रीवः। विलोहित इति वि ★ लोहितः॥ उतैनम्। एनङ्गोपाः। गोपा अदृशन्न्। गोपा इति गो ★ पाः। अदृश न्नदृशन्न्। अदृशन्नुदहार्यः। उदहार्य इत्युद ★ हार्यः॥ उतैनम्। एनं विश्वा। विश्वा भूतानि। भूतानि सः। स दृष्टः। दृष्टो मृडयाति। मृडयाति नः। न इति नः॥ नमो अस्तु। अस्तु नील ग्रीवाय। नील ग्रीवाय सहस्राक्षाय। नील ग्रीवा येति नील ★ ग्रीवाय। सहस्राक्षाय मीढुषे। सहस्राक्षा येति सहस्र ★ अक्षाय। मीढुष इति मीढुषे॥ अथो ये। अथो इत्यथो। ये अस्य। अस्य सत्वानः। सत्वा नोहम्। अहं तेभ्यः। तेभ्योऽकरम्। अकरं नमः। नम इति नमः॥ प्रमुञ्च। मुञ्च धन्वनः। धन्वन स्त्वम्। त्व मुभयोः। उभयो रार्त्नियोः। आर्त्नियोर्ज्याम्। ज्यामिति ज्याम्॥ याश्च। च ते। ते हस्ते। हस्त इषवः। इषवः परा॥३॥ परा ताः। ता भगवः। भगवोवप। भगव इति भग ★ वः। वपेति वप॥ अवतत्य धनुः। अवतत्ये त्यव ★ तत्य। धनुस्त्वम्। त्वꣳसहस्राक्ष। सहस्राक्ष शतेषुधे। सहस्राक्षेति सहस्र ★ अक्ष। शतेषुध इति शत ★ इषुधे॥ निशीर्य शल्यानाम्। निशीर्येति नि ★ शीर्य। शल्यानां मुखा। मुखा शिवः। शिवो नः। न स्सुमनाः। सुमना भव। सुमना इति सु ★ मनाः। भवेति भव॥ विज्यं धनुः। विज्य मिति वि ★ ज्यम्। धनुः कपर्दिनः। कपर्दिनो विशल्यः। विशल्यो बाणवान्। विशल्य इति वि ★ शल्यः। बाणवाꣳउत। बाणवा निति बाण ★ वान्। उतेत्युत॥ अनेशन्नस्य। अस्ये षवः।

In Public domain. Digitization Muthulakshmi Research Academy

इषव आभुः। आभु रस्य। अस्यनिषङ्गथिः। निषङ्गथि रिति निषङ्गथिः॥ यातें। ते हेतिः। हेति मींढुष्टम। मीढुष्टम हस्ते। मीढुष्टमेति मीढुः ★ तम। हस्ते बभूव। बभूव ते। ते धनुः। धनु रिति धनुः॥ तया स्मान्। अस्मान् विश्वतः। विश्व तस्त्वम्। त्वमं यक्ष्मया। अयक्ष्मया परिं। परिब्भुज। भुजेति भुज॥ नमस्ते। ते अस्तु। अस्त्वा युधाय। आयुधाया नाततायं। अनाततायं धृष्णवें। अनातता येत्यना ★ ततायं। धृष्णव इति धृष्णवें॥ उभाभ्यां मुत। उततें। ते नमः। नमों बाहुभ्याम्। बाहुभ्यां तवं। बाहुभ्या मिति बाहु ★ भ्याम्। तव धन्वने। धन्वन इति धन्वने॥ परि ते। ते धन्वनः। धन्वनो हेतिः। हेति रस्मान्। अस्मान्वृणक्तु। वृणक्तु विश्वतः। विश्वत इति विश्वतः॥ अथो यः। अथो इत्यथों। य इषुधिः। इषुधि स्तवं। इषुधि रितीषु ★ धिः। त वारे। आरे अस्मत्। अस्मन्नि। निधेहि। धेहितं। तमिति तं॥४॥

(२) नमो हिरण्य बाहवे। हिरण्य बाहवे सेनान्यें। हिरण्य बाहव इति हिरण्य ★ बाहवे। सेनान्यें दिशाम्। सेनान्य इति सेना ★ न्यें। दिशाञ्च। च पतये। पतये नमः। नमो नमः। नमों वृक्षेभ्यः। वृक्षेभ्यो हरिकेशेभ्यः। हरिकेशेभ्यः पशूनाम्। हरिकेशेभ्य इति हरि ★ केशेभ्यः। पशूनां पतये। पतये नमः। नमो नमः। नम स्सस्पिञ्जराय। सस्पिञ्जराय त्विषीमते। त्विषीमते पथीनाम्। त्विषीमत इति त्विषि ★ मते। पथीनां पतये। पतये नमः। नमो नमः। नमों बभ्लुशाय। बभ्लुशाय विव्याधिनें। विव्याधिनेन्नानाम्। विव्याधिन इति वि ★ व्याधिनें। अन्नानां

In Public domain. Digitization Muthulakshmi Research Academy

पतये। पतये नमः। नमो नमः। नमो हरिकेशाय। हरिकेशायोऽपवीतिने। हरिकेशा येति हरि ★ केशाय। उपवीतिने पुष्टानाम्। उपवीतिन इत्युप ★ वीतिने। पुष्टानां पतये। पतये नमः। नमो नमः। नमो भवस्य। भवस्य हेत्यै। हेत्यै जगताम्। जगतां पतये। पतये नमः। नमो नमः। नमो रुद्राय। रुद्रायाततताविने। आत ताविने क्षेत्राणाम्। आततताविन इत्या ★ तताविने। क्षेत्राणां पतये। पतये नमः। नमो नमः। नम स्सूताय। सूताया हन्त्याय। अहन्त्याय वनानाम्। वनानां पतये। पतये नमः। नमो नमः। नमो रोहिताय॥५॥ रोहिताय स्थपतये। स्थपतये वृक्षाणाम्। वृक्षाणां पतये। पतये नमः। नमो नमः। नमो मन्त्रिणे। मन्त्रिणे वाणिजाय। वाणिजाय कक्षाणाम्। कक्षाणां पतये। पतये नमः। नमो नमः। नमो भुवन्तये। भुवन्तये वारिवस्कृताय। वारिवस्कृता यौषधीनाम्। वारिवस्कृता येति वारिवः ★ कृताय। ओषधीनां पतये। पतये नमः। नमो नमः। नम उच्चै र्घोषाय। उच्चैर्घोषाया क्रन्दयते। उच्चैर्घोषाये त्युच्चैः ★ घोषाय। आक्रन्दयते पत्तीनाम्। आक्रन्दयत इत्या ★ क्रन्दयते। पत्तीनां पतये। पतये नमः। नमो नमः। नमः कृत्स्न- वीताय। कृत्स्नवीताय धावते। कृत्स्नवीता येति कृत्स्न ★ वीताय। धावते सत्वनाम्। सत्वनां पतये। पतये नमः। नम इति नमः॥

(३) नम स्सहमानाय। सहमानाय निव्याधिने। निव्याधिन आव्याधिनीनाम्। निव्याधिन इति नि ★ व्याधिने। आव्याधिनीनां पतये। आव्याधिनीना मित्या ★ व्याधिनीनाम्। पतये नमः। नमो

In Public domain. Digitization Muthulakshmi Research Academy

नमः। नमः ककुभाय। ककुभाय निषङ्गिणे। निषङ्गिणे स्तेनानाम्। निषङ्गिण इति नि ★ सङ्गिने। स्तेनानां पतये। पतये नमः। नमो नमः। नमो निषङ्गिणे। निषङ्गिण इषुधिमते। निषङ्गिण इति नि ★ सङ्गिने। इषुधिमते तस्कराणाम्। इषुधिमत इतीषुधि ★ मते। तस्कराणां पतये। पतये नमः। नमो नमः। नमो वञ्चते। वञ्चते परिवञ्चते। परिवञ्चते स्तायूनाम्। परिवञ्चत इति परि ★ वञ्चते। स्तायूनां पतये। पतये नमः। नमो नमः। नमो निचेरवे। निचेरवे परिचराय। निचेरव इतिनि ★ चेरवे। परिचराया रण्यानाम्। परिचरायेति परि ★ चराय। अरण्यानां पतये। पतये नमः। नमो नमः। नमः स्सृकाविभ्यः। सृकाविभ्यो जिघाꣳसद्भ्यः। सृकाविभ्य इति सृकावि ★ भ्यः। जिघाꣳ-सद्भ्योमुष्णताम्। जिघाꣳसद्भ्य इति जिघाꣳ सत् ★ भ्यः। मुष्णतां पतये। पतये नमः। नमो नमः। नमोऽ सिमद्भ्यः। असिमद्भ्यो नक्तम्। असिमद्भ्य इत्यसिमत् ★ भ्यः। नक्तं चरद्भ्यः। चरद्भ्यः प्रकृन्तानाम्। चरद्भ्य इति चरत् ★ भ्यः। प्रकृन्तानां पतये। प्रकृन्ताना मिति प्र ★ कृन्तानाम्। पतये नमः। नमो नमः। नमः उष्णीषिणे। उष्णीषिणे गिरिचराय। गिरिचराय कुलुञ्चानाम्। गिरिचरायेति गिरि ★ चराय। कुलुञ्चानां पतये। पतये नमः। नमो नमः। नम इषुमद्भ्यः॥ इषुमद्भ्यो धन्वाविभ्यः। इषुमद्भ्य इतीषुमत् ★ भ्यः। धन्वाविभ्यश्च। धन्वाविभ्य इति धन्वावि ★ भ्यः। च वः। वो नमः। नमो नमः। नम आतन्वानेभ्यः। आतन्वानेभ्यः प्रतिदधानेभ्यः। आतन्वानेभ्य इत्या

In Public domain. Digitization Muthulakshmi Research Academy

★ तन्वानेभ्यः। प्रतिदधानेभ्यश्च। प्रति दधानेभ्य इति प्रति ★ दधानेभ्यः। च वः। वो नमः। नमो नमः। नम आयच्छद्भ्यः। आयच्छद्भ्यो विसृजद्भ्यः। आयच्छद्भ्य इत्या यच्छत् ★ भ्यः। विसृजद्भ्यश्च। विसृजद्भ्य इति विसृजत् ★ भ्यः। च वः। वो नमः। नमो नमः। नमोऽस्यद्भ्यः। अस्यद्भ्यो विध्यद्भ्यः। अस्यद्भ्य इत्यस्यत् ★ भ्यः। विध्यद्भ्यश्च। विध्यद्भ्य इति विध्यत् ★ भ्यः। च वः। वो नमः। नमो नमः। नम आसीनेभ्यः। आसीनेभ्य श्शयानेभ्यः। शयानेभ्यश्च। च वः। वो नमः। नमो नमः। नमः स्वपद्भ्यः। स्वपद्भ्यो जाग्रद्भ्यः। स्वपद्भ्य इति स्वपत् ★ भ्यः। जाग्रद्भ्यश्च। जाग्रद्भ्य इति जाग्रत् ★ भ्यः। च वः। वो नमः। नमो नमः। नमस्तिष्ठद्भ्यः। तिष्ठद्भ्यो धावद्भ्यः। तिष्ठद्भ्य इति तिष्ठत् ★ भ्यः। धावद्भ्यश्च। धावद्भ्य इति धावत् ★ भ्यः। च वः। वो नमः। नमो नमः। नम स्सभाभ्यः। सभाभ्य स्सभापतिभ्यः। सभापतिभ्यश्च। सभापतिभ्य इति सभापति ★ भ्यः। च वः। वो नमः। नमो नमः। नमो अश्वेभ्यः। अश्वेभ्योऽश्वपतिभ्यः। अश्वपतिभ्यश्च। अश्वपतिभ्य इत्यश्वपति ★ भ्यः। च वः। वो नमः। नम इति नमः॥

(४) नम आव्याधिनीभ्यः। आव्याधिनीभ्यो विविध्यन्ती-भ्यः। आव्याधिनीभ्य इत्या ★ व्याधिनीभ्यः। विविध्यन्ती-भ्यश्च। विविध्यन्तीभ्य इति वि ★ विध्यन्तीभ्यः। च वः। वो नमः। नमो नमः। नम उगणाभ्यः। उगणाभ्य स्तृꣳहतीभ्यः। तृꣳहतीभ्यश्च। च वः। वो नमः। नमो नमः। नमो गृत्सेभ्यः।

In Public domain. Digitization Muthulakshmi Research Academy

गृथ्सेभ्यो गृथ्सपतिभ्यः। गृथ्सपतिभ्यश्च। गृथ्सपतिभ्य इति गृथ्सपति ★ भ्यः। च वः। वो नमः। नमो नमः। नमो व्रातेभ्यः। व्रातेभ्यो व्रातपतिभ्यः। व्रात पतिभ्यश्च। व्रातपतिभ्य इति व्रातपति ★ भ्यः। च वः। वो नमः। नमो नमः। नमो गणेभ्यः। गणेभ्यो गणपतिभ्यः। गणपतिभ्यश्च। गणपतिभ्य इति गणपति ★ भ्यः। च वः। वो नमः। नमो नमः। नमो विरूपेभ्यः। विरूपेभ्यो विश्व रूपेभ्यः। विरूपेभ्य इति वि ★ रूपेभ्यः। विश्व रूपेभ्यश्च। विश्वरूपेभ्य इति विश्व ★ रूपेभ्यः। च वः। वो नमः। नमो नमः। नमो महद्भ्यः। महद्भ्यः क्षुल्लकेभ्यः। महद्भ्य इति महत् ★ भ्यः। क्षुल्लकेभ्यश्च। च वः। वो नमः। नमो नमः। नमो रथिभ्यः। रथिभ्योऽरथेभ्यः। रथिभ्य इति रथि ★ भ्यः। अरथेभ्यश्च। च वः। वो नमः। नमो नमः। नमो रथेभ्यः। रथेभ्यो रथपतिभ्यः॥ रथपतिभ्यश्च। रथपतिभ्य इति रथपति ★ भ्यः। च वः। वो नमः। नमो नमः। नम स्सेनाभ्यः। सेनाभ्य स्सेनानिभ्यः। सेनानिभ्यश्च। सेनानिभ्य इति सेनानि ★ भ्यः। च वः। वो नमः। नमो नमः। नमः क्षत्तृभ्यः॥ क्षत्तृभ्य स्संग्रहीतृभ्यः। क्षत्तृभ्य इति क्षत्तृ ★ भ्यः। संग्रहीतृभ्यश्च। संग्रहीतृभ्य इति संग्रहीतृ ★ भ्यः। च वः। वो नमः। नमो नमः। नम स्तक्षभ्यः। तक्षभ्यो रथकारेभ्यः। तक्षभ्य इति तक्ष ★ भ्यः। रथकारेभ्यश्च। रथकारेभ्य इति रथ ★ कारेभ्यः। च वः। वो नमः। नमो नमः। नमः कुलालेभ्यः। कुलालेभ्यःकर्मारेभ्यः। कर्मारेभ्यश्च। च वः। वो नमः। नमो नमः। नमः पुञ्जिष्टेभ्यः। पुञ्जिष्टेभ्यो निषादेभ्यः। निषा

In Public domain. Digitization Muthulakshmi Research Academy

देभ्यश्च। च वः। वो नमः। नमो नमः। नम इषुकृद्भ्यः। इषुकृद्भ्यो धन्वकृद्भ्यः। इषुकृद्भ्य इतीषुकृत् ★ भ्यः। धन्व- कृद्भ्यश्च। धन्वकृद्भ्य इति धन्वकृत् ★ भ्यः। च वः। वो नमः। नमो नमः। नमो मृगयुभ्यः। मृगयुभ्यः श्वनिभ्यः। मृगयुभ्य इति मृगयु ★ भ्यः। श्वनिभ्यश्च। श्वनिभ्य इति श्वनि ★ भ्यः। च वः। वो नमः। नमो नमः। नमः श्वभ्यः। श्वभ्य श्वपतिभ्यः। श्वभ्य इति श्व ★ भ्यः। श्वपतिभ्यश्च। श्वपतिभ्य इति श्वपति ★ भ्यः। च वः। वो नमः। नम इति नमः॥

(५) नमो भवाय। भवाय च। च रुद्राय। रुद्राय च। च नमः। नम श्शर्वाय। शर्वाय च। च पशुपतये। पशुपतये च। पशुपतय इति पशु ★ पतये। च नमः। नमो नीलग्रीवाय। नीलग्रीवाय च। नीलग्रीवायेति नील ★ ग्रीवाय। च शिति कण्ठाय। शिति कण्ठाय च। शिति कण्ठायेति शिति ★ कण्ठाय। च नमः। नमः कपर्दिने। कपर्दिने च। च व्युप्त- केशाय। व्युप्तकेशाय च। व्युप्तकेशा येति व्युप्त ★ केशाय। च नमः। नम स्सहस्राक्षाय। सहस्राक्षाय च। सहस्राक्षा येति सहस्र ★ अक्षाय। च शत धन्वने। शतधन्वने च। शत धन्वन इति शत ★ धन्वने। च नमः। नमो गिरिशाय। गिरिशाय च। च शिपि विष्टाय। शिपि विष्टाय च। शिपिविष्टायेति शिपि ★ विष्टाय। च नमः। नमो मीढुष्टमाय। मीढुष्टमाय च। मीढुष्टमा येति मीढुः ★ तमाय। चेषुमते। इषुमते च। इषुमत इतीषु ★ मते। च नमः। नमो ह्रस्वाय। ह्रस्वाय च। च वामनाय। वामनाय च। च नमः।

In Public domain. Digitization Muthulakshmi Research Academy

नमो बृहते। बृहते च। च वर्षीयसे। वर्षीयसे च। च नमः। नमो वृद्धाय। वृद्धाय च। च संवृध्वने। संवृध्वने च। संवृध्वन इति सं ★ वृध्वने। च नमः॥ नमो अग्रियाय। अग्रियाय च। च प्रथमाय। प्रथमाय च। च नमः। नम आशवे। आशवे च। चाऽजिराय। अजिराय च। च नमः। नम श्शीघ्रियाय। शीघ्रियाय च। च शीभ्याय। शीभ्याय च। च नमः। नम ऊर्म्याय। ऊर्म्याय च। चा वस्वन्याय। अवस्वन्याय च। अवस्वन्या येत्यव ★ स्वन्याय। च नमः। नम स्स्रोतस्याय। स्रोत- स्याय च। चद्वीप्याय। द्वीप्याय च। चेति च॥

(६) नमो ज्येष्ठाय। ज्येष्ठाय च। च कनिष्ठाय। कनिष्ठाय च। च नमः। नमः पूर्वजाय। पूर्वजाय च। पूर्वजायेति पूर्व ★ जाय। चा परजाय। अपरजाय च। अपर जायेत्य पर ★ जाय। च नमः। नमो मध्यमाय। मध्यमाय च। चापगल्भाय। अपगल्भाय च। अपगल्भा येत्यप ★ गल्भाय। च नमः। नमो जघन्याय। जघन्याय च। च बुध्नियाय। बुध्नियाय च। च नमः। नम स्सोभ्याय। सोभ्याय च। चप्रतिसर्याय। प्रतिसर्याय च। प्रतिसर्या येति प्रति ★ सर्याय। च नमः। नमो याम्याय। याम्याय च। च क्षेम्याय। क्षेम्याय च। च नमः। नम उर्वर्याय। उर्वर्याय च। च खल्याय। खल्याय च। च नमः। नम श्श्लोक्याय। श्लोक्याय च। चा वसान्याय। अवसान्याय च। अवसान्या येत्यव ★ सान्याय। च नमः। नमो वन्याय। वन्याय च। च कक्ष्याय। कक्ष्याय च। च नमः। नमश्श्रवाय। श्रवाय च। च प्रति श्रवाय।

In Public domain. Digitization Muthulakshmi Research Academy

प्रति श्रवाय च। प्रतिश्रवा येति प्रति ★ श्रवाय। च नमः॥ नम आशुषेणाय। आशुषेणाय च। आशुषेणा येत्याशु ★ सेनाय। चाशुरथाय। आशुरथाय च। आशुरथा येत्याशु ★ रथाय। च नमः। नम श्शूराय। शूराय च। चाव भिन्दते। अव भिन्दते च। अवभिन्दत इत्यव ★ भिन्दते। च नमः। नमो वर्मिणे। वर्मिणे च। च वरूथिने। वरूथिनेच। च नमः। नमो बिल्मिने। बिल्मिने च। च कवचिने। कवचिने च। च नमः। नमःश्रुताय। श्रुताय च। च श्रुत सेनाय। श्रुत सेनाय च। श्रुतसेनायेति श्रुत ★ सेनाय। चेति च॥

(७) नमो दुन्दुभ्याय। दुन्दुभ्याय च। चा हनन्याय। आहनन्याय च। आहनन्या येत्या ★ हनन्याय। च नमः। नमो धृष्णवे। धृष्णवे च। च प्रमृशाय। प्रमृशाय च। प्रमृशायेति प्र ★ मृशाय। च नमः। नमो दूताय। दूताय च। च प्रहिताय। प्रहिताय च। प्रहिता येति प्र ★ हिताय। च नमः। नमो निषङ्गिणे। निषङ्गिणे च। निषङ्गिण इतिनि ★ सङ्गिने। चे षुधिमते। इषुधिमते च। इषुधिमत इतीषुधि ★ मते। च नमः। नम स्तीक्ष्णेषवे। तीक्ष्णेषवे च। तीक्ष्णेषव इति तीक्ष्ण ★ इषवे। चा युधिने। आयुधिने च। च नमः। नम स्स्वायुधाय। स्वायुधाय च। स्वायुधा येति सु ★ आयुधाय। च सुधन्वने। सुधन्वने च। सुधन्वन इति सु ★ धन्वने। च नमः। नम स्स्रुत्याय। स्रुत्याय च। च पथ्याय। पथ्याय च। च नमः। नमः काट्याय । काट्याय च। च नीप्याय। नीप्याय च। च नमः। नम सूद्याय। सूद्याय च। च सरस्याय। सरस्याय च। च

In Public domain. Digitization Muthulakshmi Research Academy

नमः। नमो नाद्याय। नाद्याय च। च वैशन्ताय। वैशन्ताय च। च नमः॥ नमः कूप्याय। कूप्याय च। चा वर्ष्याय। अवर्ष्याय च। च नमः। नमो वर्ष्याय। वर्ष्याय च। चा वर्ष्याय। अवर्ष्याय च। च नमः। नमो मेघ्याय। मेघ्याय च। च विद्युत्याय। विद्युत्याय च। विद्युत्या येति वि ★ द्युत्याय। च नमः। नम ईध्रियाय। ईध्रियाय च। चातप्याय। आतप्याय च। आतप्या येत्या ★ तप्याय। च नमः। नमो वात्याय। वात्याय च। च रेष्मियाय। रेष्मियाय च। च नमः। नमो वास्तव्याय। वास्तव्याय च। च वास्तुपाय। वास्तुपाय च। वास्तुपा येति वास्तु ★ पाय। चेति च॥

(८) नम स्सोमाय। सोमाय च। च रुद्राय। रुद्राय च। च नमः। नम स्ताम्राय। ताम्राय च। चा रुणाय। अरुणाय च। च नमः। नम श्शङ्गाय। शङ्गाय च। च पशुपतये। पशुपतये च। पशुपतय इति पशु ★ पतये। च नमः। नम उग्राय। उग्राय च। च भीमाय। भीमाय च। च नमः। नमो अग्रे वधाय। अग्रे वधाय च। अग्रे वधा येत्यग्रे ★ वधाय। च दूरेवधाय। दूरेवधाय च। दूरेवधा येति दूरे ★ वधाय। च नमः। नमो हन्त्रे। हन्त्रे च। च हनीयसे। हनीयसे च। च नमः। नमो वृक्षेभ्यः। वृक्षेभ्यो हरिकेशेभ्यः। हरिकेशेभ्यो नमः। हरिकेशेभ्य इति हरि ★ केशेभ्यः। नम स्ताराय। ताराय नमः। नम श्शं भवे। शंभवे च। शंभव इति शं ★ भवे। च मयोभवे। मयो भवे च। मयोभव इति मयः ★ भवे। च नमः। नम श्शंकराय। शंकराय च। शंकरा येति शं ★ कराय। च मयस्कराय। मय स्कराय च। मयस्करायेति मयः ★

In Public domain. Digitization Muthulakshmi Research Academy

करायं। च नमः। नमं शिशवायं। शिवायं च। च शिवतंराय। शिवतंराय च। शिवतंरायेति शिव ★ तराय। च नमः॥ नम स्तीर्थ्यांय। तीर्थ्यांय च! च कूल्यांय। कूल्यांय च। च नमः। नमः पार्यांय। पार्यांय च। चा वार्यांय। अवा- र्यांय च। च नमः। नमः प्रतरंणाय। प्रतरंणाय च। प्रतरंणा येति प्र ★ तरंणाय। चोऽत्तरंणाय। उत्तरंणाय च। उत्तरंणा येत्युत् ★ तरंणाय। च नमः। नमं आतार्यांय। आतार्यांय च। आतार्यां येत्यां ★ तार्यांय। चा लाद्यांय। आलाद्यांय च। आलाद्यां येत्यां ★ लाद्यांय। च नमः। नम श्शष्प्यांय। शष्प्यांय च। च फेन्यांय। फेन्यांय च। च नमः। नमं स्सिकत्यांय। सिकत्यांय च। च प्रवाह्यांय। प्रवाह्यांय च। प्रवाह्यां येति प्र ★ वाह्यांय। चेति च॥

(९) नमं इरिण्यांय। इरिण्यांय च। च प्रपथ्यांय। प्रपथ्यांय च। प्रपथ्यां येति प्र ★ पथ्यांय। च नमः। नमः किंः शिलायं। किंः शिलायं च। च क्षयंणाय। क्षयंणाय च। च नमः। नमः कपर्दिनें। कपर्दिनें च। च पुलस्तयें। पुलस्तयें च। च नमः। नमो गोष्ठ्यांय। गोष्ठ्यांय च। गोष्ठ्या येति गो ★ स्थ्याय। च गृह्यांय। गृह्यांय च। च नमः। नम स्तल्प्यांय। तल्प्यांय च। च गेह्यांय। गेह्यांय च। च नमः। नमः काट्यांय। काट्यांय च। च गह्वरेष्ठायं। गह्वरेष्ठायं च। गह्वरेष्ठा येति गह्वरे ★ स्थायं। च नमः। नमों ह्रदय्यांय। ह्रदय्यांय च। च निवेष्प्यांय। निवेष्प्यांय च। निवेष्प्यां येति नि ★ वेष्प्यांय। च नमः। नमः पांःसव्यांय। पांःसव्यांय च । च रजस्यांय। रजस्यांय च। च नमः। नम

In Public domain. Digitization Muthulakshmi Research Academy

शशुष्क्याय। शुष्क्याय च। च हरि त्याय। हरित्याय च। च नमः। नमो लोप्याय। लोप्याय च। चोऽलप्याय। उलप्याय च। च नमः॥ नम ऊर्व्याय। ऊर्व्याय च। च सूर्म्याय। सूर्म्याय च। च नमः। नमः पर्ण्याय। पर्ण्याय च। च पर्णशद्याय। पर्णशद्याय च। पर्णशद्यायेति पर्ण ★ शद्याय। च नमः। नमोऽपगुरमाणाय। अपगुरमाणाय च। अपगुरमाणा येत्यप ★ गुरमाणाय। चाऽभिघ्नते। अभिघ्नते च। अभिघ्नत इत्यभि ★ घ्नते। च नमः। नम आक्खिदते। आक्खिदते च। आक्खिदत इत्या ★ खिदते। च प्रक्खिदते। प्रक्खिदते च। प्रक्खिदत इति प्र ★ खिदते। च नमः। नमो वः। वः किरिकेभ्यः। किरिकेभ्यो देवानाम्। देवाना ँहृदयेभ्यः। हृदयेभ्यो नमः। नमो विक्षीणकेभ्यः। विक्षीणकेभ्यो नमः। विक्षीणकेभ्य इति वि ★ क्षीणकेभ्यः। नमो विचिन्वत्केभ्यः। विचिन्वत्केभ्यो नमः। विचिन्वत्केभ्य इति वि ★ चिन्वत्केभ्यः। नमः आनिर्हतेभ्यः। आनिर्हतेभ्यो नमः। आनिर्हतेभ्य इत्यानिः ★ हतेभ्यः। नम आमीवत्केभ्यः। आमीवत्केभ्य इत्या ★ मीवत्केभ्यः॥

(१०) द्रापे अन्धसः। अन्धसस्पते। पते दरिद्रत्। दरिद्र-न्नीललोहित। नील लोहितेति नील ★ लोहित॥ एषां पुरुषाणाम्। पुरुषाणा मेषाम्। एषां पशूनाम्। पशूनां मा। मा भेः। भेर्मा। मा रः। अरोमो। मो एषाम्। मो इति मो। एषां किम्। किञ्चन। चना ममत्। आमम दित्या ममत्॥ याते। ते रुद्र। रुद्र शिवा। शिवा तनूः। तनू श्शिवा। शिवा विश्वाहभेषजी। विश्वाह भेषजीति

In Public domain. Digitization Muthulakshmi Research Academy

विश्वाहं ★ भेषजी॥ शिवा रुद्रस्यं। रुद्रस्यं भेषजी। भेषजी तयां। तयां नः। नो मृड। मृड जीवसें॥ जीवस इतिं जीवसें॥ इमा रुद्रायं। रुद्रायं तवसें। तवसें कपर्दिनें। कपर्दिनें क्षयद्वीराय। क्षयद्वीराय प्र। क्षयद्वीरायेतिं क्षयत् ★ वीराय। प्रभंरा महे। भरामहे मतिम्। मति मितिं मतिम्॥ यथां नः। न श्शम्। शम संत्। असंद् द्विपदें। द्विपदे चतुंष्पदे। द्विपद इतिं द्वि ★ पदें। चतुंष्पदे विश्वम्। चतुष्पद इति चतुः ★ पदे। विश्वं पुष्टम्। पुष्टं ग्रामें। ग्रामें अस्मिन्। अस्मिन्ननांतुरम्॥ अनांतुर मित्यनां ★ तुरम्। मृडानंः। नो रुद्र। रुद्रोत। उत नंः। नो मयंः। मयं स्कृधि। कृधि क्षयद्वीराय। क्षयद्वीराय नमंसा। क्षयद्वीरा येतिं क्षयत् ★ वीराय। नमंसा विधेम। विधेम ते। त इतिं ते॥ यच्छम्। शञ्चं। च योः। योश्चं। च मनुंः। मनुं रायजे। आयजे पिता। आयज इत्यां ★ यजे। पिता तत्। तदंश्याम। अश्याम तवं। तवं रुद्र। रुद्र प्रणींतौ। प्रणींता वितिं प्र ★ नीतौ। मानंः। नो महान्तम्। महान्तं मुत। उत मा। मा नंः। नो अर्भकम्। अर्भकं मा। मा नंः। न उक्षंन्तम्। उक्षंन्त मुत। उत मा। मा नंः। न उक्षितम्। उक्षित मित्युं क्षितम्। मा नंः। नो वधीः। वधीः पितरम्। पितरं मा। मो त। उत मातरम्। मातरं प्रियाः। प्रिया मा। मा नंः। न स्तनुवंः। तनुवों रुद्र। रुद्ररीरिषः। रीरिष इतिं रीरिषः॥ मा नंः। न स्तोके। तोके तनंये। तनंये मा। मा नंः। न आयुंषि। आयुंषि मा। मा नंः। नो गोषुं। गोषु मा। मा नंः। नो अश्वेषु। अश्वेषु रीरिषः। रीरिष इतिं रीरिषः। वी रान्मा। मा नंः। नो रुद्र। रुद्रभामितः। भामितो

In Public domain. Digitization Muthulakshmi Research Academy

वधीः। वधी र्हविष्मन्तः। हविष्मन्तो नमसा। नमसा विधेम। विधेम ते। त इति ते॥ आरात्ते। ते गोघ्ने। गोघ्न उत। गोघ्न इति गो ★ घ्ने। उत पूरुषघ्ने। पूरुषघ्ने क्षयद्वीराय। पूरुषघ्न इति पूरुष ★ घ्ने। क्षयद्वीराय सुम्नम्। क्षयद्वीरायेति क्षयत् ★ वीराय। सुम्नमस्मे। अस्मे ते। अस्मे इत्यस्मे। ते अस्तु। अस्त्वित्यस्तु॥ रक्षा च। च नः। नो अधि। अधि च। च देव। देव ब्रूहि। ब्रूह्यध। अधा च। च नः। न श्शर्म। शर्म यच्छ। यच्छ द्विबर्हाः। द्वि बर्हा इति द्वि ★ बर्हाः॥ स्तुहि श्रुतम्॥ श्रुतं गर्त सदम्। गर्त सदं युवानम्। गर्त सद मिति गर्त ★ सदम्। युवानं मृगम्। मृगं न। न भीमम्। भीममुपहत्नुम्। उपहत्नु मुग्रम्। उग्र मित्युग्रम्॥ मृडा जरित्रे। जरित्रे रुद्र। रुद्र स्तवानः। स्तवानो अन्यम्। अन्यन्ते। ते अस्मत्। अस्मन्नि। निवपन्तु। वपन्तु सेनाः। सेना इति सेनाः। परिणः। नो रुद्रस्य। रुद्रस्य हेतिः। हेति र्वृणक्तु। वृणक्तु परि। परित्वेषस्य। त्वेषस्य दुर्मतिः। दुर्मतिर घायोः। दुर्मति रिति दुः ★ मतिः। अघायो रित्यघ ★ योः॥ अवस्थिरा। स्थिरा मघवद्भ्यः। मघवद्भ्य स्तनुष्व। मघवद्भ्य इति मघवत् ★ भ्यः। तनुष्व मीढ्वः। मीढ्वस्तोकाय। तोकाय तनयाय। तनयाय मृडय। मृडयेति मृडय॥ मीढुष्टम शिवतम। मीढुष्ट मेति मीढुः ★ तम। शिवतम शिवः। शिवत मेति शिव ★ तम। शिवो नः। न स्सुमनाः। सुमना भव। सुमना इति सु ★ मनाः। भवेति भव॥ परमे वृक्षे। वृक्ष आयुधम्। आयुधं निधाय। निधाय कृत्तिम्। निधायेति नि ★ धाय। कृत्तिं वसानः। वसान आ। आ चर। चर

In Public domain. Digitization Muthulakshmi Research Academy

पिनाकम्। पिनाकं बिभ्रत्॥ बिभ्रदा। आगहि। गहीति गहि॥ विकिरिद विलोहित। विकिरि देति वि ★ किरिद। विलोहित नमः। विलोहितेति वि ★ लोहित। नमस्ते। ते अस्तु। अस्तु भगवः। भगव इति भग ★ वः॥ यास्ते। ते सहस्रम्। सहस्रꣳ हेतयः। हेतयो न्यम्। अन्य मस्मत्। अस्मन्नि। नि वपन्तु। वपन्तु ताः। ता इति ताः॥ सहस्राणि सहस्रधा। सहस्रधा बाहुवोः। सहस्र धेति सहस्र ★ धा। बाहुवो स्तव। तव हेतयः। हेतय इति हेतयः॥ तासा मीशानः। ईशानो भगवः। भगवः पराचीना। भगव इति भग ★ वः॥ पराचीना मुखा। मुखा कृधि। कृधीति कृधि॥

(११) सहस्राणि सहस्रशः। सहस्रशो ये। सहस्रश इति सहस्र ★ शः। ये रुद्रा। रुद्रा अधि। अधि भूम्याम्। भूम्या मिति भूम्याम्॥ तेषाꣳ सहस्र योजने। सहस्र योजने व। सहस्र योजन इति सहस्र ★ योजने। अव धन्वानि। धन्वानि तन्मसि। तन्मसीति तन्मसि॥ अस्मि न्महति। महत्यर्णवे। अर्णवेऽन्तरिक्षे। अन्तरिक्षे भवाः। भवा अधि। अधीत्यधि॥ नीलग्रीवा शितिकण्ठाः। नीलग्रीवा इति नील ★ ग्रीवाः। शितिकण्ठाश्शर्वाः। शितिकण्ठा इति शिति ★ कण्ठाः। शर्वा अधः। अधः क्षमाचराः। क्षमा चरा इति क्षमाचराः। नीलग्रीवा शितिकण्ठाः। नीलग्रीवा इति नील ★ ग्रीवाः। शितिकण्ठा दिवम्। शितिकण्ठा इति शिति ★ कण्ठाः। दिवꣳ रुद्राः। रुद्रा उपश्रिताः। उपश्रिता इत्युप ★ श्रिताः। ये वृक्षेषु। वृक्षेषु सस्पिञ्जराः। सस्पिञ्जरा नीलग्रीवाः। नीलग्रीवा विलोहिताः। नीलग्रीवा इति नील ★ ग्रीवाः। विलोहिता

In Public domain. Digitization Muthulakshmi Research Academy

इति वि ★ लोहिताः॥ ये भूतानाम्। भूताना मधिपतयः। अधिपतयो विशिखासः। अधिपतय इत्यधि ★ पतयः। विशिखासः कपर्दिनः। विशिखास इति वि ★ शिखासः। कपर्दिन इति कपर्दिनः॥ ये अन्नेषु। अन्नेषु विविध्यन्ति। विविध्यन्ति पात्रेषु। विविध्यन्तीति वि ★ विध्यन्ति। पात्रेषु पिबतः। पिबतो जनान्। जना निति जनान्॥ ये पथाम्। पथां पथिरक्षयः। पथिरक्षय ऐलबृदाः। पथिरक्षय इति पथि ★ रक्षयः। ऐलबृदा यव्युधः। यव्युध इति यव्युधः॥ ये तीर्थानि। तीर्थानि प्रचरन्ति॥ प्रचरन्ति सृकावन्तः। प्रचरन्तीति प्र ★ चरन्ति। सृकावन्तो निषङ्गिणः। सृकावन्त इति सृका ★ वन्तः। निषङ्गिण इतिनि ★ सङ्गिनः। य एतावन्तः। एतावन्तश्च। च भूया ँ सः। भूया ँ सश्च। च दिशः। दिशो रुद्राः। रुद्रा वितस्थिरे। वितस्थिर इतिवि ★ तस्थिरे॥ तेषा ँ सहस्र योजने। सहस्र योजने व। सहस्र योजन इति सहस्र ★ योजने। अव धन्वानि। धन्वानि तन्मसि। तन्मसीति तन्मसि॥ नमो रुद्रेभ्यः। रुद्रेभ्यो ये। ये पृथिव्याम्। पृथिव्यां ये। ये॑न्तरिक्षे। अन्तरिक्षे ये। ये दिवि। दिवि येषाम्। येषा मन्नम्। अन्नं वातः। वातो वर्षम्। वर्ष- मिषवः। इषवस्तेभ्यः। तेभ्यो दश। दश प्राचीः। प्राचीर्दश। दश दक्षिणा। दक्षिणा दश। दश प्रतीचीः। प्रतीचीर्दश। दशो- ऽदीचीः। उदीची र्दश। दशोर्ध्वाः। ऊर्ध्वा स्तेभ्यः। तेभ्यो नमः। नमस्ते। ते नः। नो मृडयन्तु। मृडयन्तु ते। ते यं। यं द्विष्मः। द्विष्मो यः। यश्च। च नः। नो द्वेष्टि। द्वेष्टि तम्। तं वः। वो जम्भे। जम्भे दधामि। दधामीति दधामि॥

In Public domain. Digitization Muthulakshmi Research Academy

त्र्यँबकं यजामहे। त्र्यँबक मिति त्रि ★ अंबकम्। यजामहे सुगन्धिम्। सुगन्धिं पुंष्टिवर्द्धँनम्। सुगन्धिमितिंसु ★ गन्धिम्। पुष्टिवर्द्धँन मितिं पुष्टि ★ वर्द्धँनम्॥ उर्वारुक मिंव। इव बन्धनात्। बन्धनान्मृत्योः। मृत्योर्मुँक्षीय। मुक्षीय मा। माऽमृताँत्। अमृता दित्य मृताँत्॥ यो रुद्रः। रुद्रो अग्नौ। अग्नौ यः। यो अप्सु। अप्सु यः। अप्स्वित्यप् ★ सु। य ओषधीषु। ओषधीषु यः। यो रुद्रः। रुद्रो विश्वाँ। विश्वा भुवना। भुवनाऽविवेश। आविवेश तस्मैँ। आविवेशेत्याँ ★ विवेश। तस्मै रुद्राय। रुद्राय नमः। नमो अस्तु। अस्त्वित्यस्तु॥

तमुंष्टुहि। उं इत्युमँ्। स्तुहि यः। यस्स्विषुः। स्विषु स्सुधन्वाँ। स्विषुरितिं सु-इषुः। सुधन्वा यः। सुधन्वेतिं सु- धन्वाँ। यो विश्वस्य। विश्वस्य क्षयति। क्षयति भेषजस्य। भेषजस्येतिं भेष ★ जस्य॥ यक्ष्वाँमहे। महे सौँमनसाय। सौमनसाय रुद्रम्। रुद्रं नमोंभिः। नमोंभि र्देवम्। नमोंभि रिति नमः ★ भिः। देव मसुरम्। असुरं दुवस्य। दुवस्येतिं दुवस्य॥ अयं मेँ। मे हस्तः। हस्तो भगवान्। भगवानयम्। भगवा निति भग ★ वान्। अयं मेँ। मे भगवत्तरः। भगवत्तर इति भगवत् ★ तरः॥ अयं मेँ। मे विश्व भैंषजः। विश्व भैंषजो यम्। विश्व भैंषज इतिं विश्व ★ भेषजः। अय ँशिवाभिं मर्शनः। शिवाभिमर्शन इतिं शिव ★ अंभिमर्शनः॥

ओं शान्तिः शान्तिः शान्तिः॥

In Public domain. Digitization Muthulakshmi Research Academy

॥ श्री चमक क्रम पाठः ॥

(१) अग्ना विष्णू सजोषसा। अग्ना विष्णू इत्यग्नां– विष्णू। सजोष सेमाः। सजोष सेति स ★ जोषसा। इमा वर्द्धन्तु। वर्द्धन्तु वाम्। वां गिरः। गिर इति गिरः॥ द्युम्नै र्वाजेभिः। वाजे भिरा। आगतम्। गतमिति गतम्॥ वाजश्च। च मे। मे प्रसवः। प्रसवश्च। प्रसव इतिप्र ★ सवः। च मे। मे प्रयतिः। प्रयतिश्च। प्रयति रिति प्र ★ यतिः। च मे। मे प्रसितिः। प्रसितिश्च। प्रसिति रिति प्र ★ सितिः। चमे। मे धीतिः। धीतिश्च। च मे। मे क्रतुः। क्रतुश्च। च मे। मे स्वरः। स्वरश्च। च मे। मे श्लोकः। श्लोकश्च। च मे। मे श्रावः। श्रावश्च। च मे। मे श्रुतिः। श्रुतिश्च। च मे। मे ज्योतिः। ज्योतिश्च। च मे। मे सुवः। सुवश्च। च मे। मे प्राणः। प्राणश्च। प्राण इति प्र ★ अनः। चमे। मेऽपानः। अपानश्च। अपान इत्यप ★ अनः॥ चमे। मे व्यानः। व्यानश्च। व्यान इति वि ★ अनः। च मे। मेऽसुः। असुश्च। चमे। मे चित्तम्। चित्तञ्च। चमे। म आधीतम्। आधीतञ्च। आधीत मित्यां ★ धीतम्। च मे। मे वाक्। वाक्च। च मे। मे मनः। मनश्च। चमे। मे चक्षुः। चक्षुश्च। चमे। मे श्रोत्रम्। श्रोत्रञ्च। चमे। मे दक्षः। दक्षश्च। चमे। मे बलम्। बलञ्च। चमे। म ओजः। ओजश्च। च मे। मे सहः। सहश्च। चमे। म आयुः। आयुश्च। च मे। मे जरा। जरा च। च मे। म आत्मा। आत्मा च। चमे। मे तनूः। तनूश्च। च मे। मे शर्म। शर्म च। च मे। मे वर्म। वर्म च। च मे। मेऽङ्गानि। अङ्गानि च।

In Public domain. Digitization Muthulakshmi Research Academy

च मे। मेऽस्थानि। अस्थानि च। च मे। मे परूꣳषि। परूꣳषि च। च मे। मे शरीराणि। शरीराणि च। चमे। म इति मे॥

(२) ज्यैष्ठ्यञ्च। चमे। म आधिपत्यम्। आधिपत्यञ्च। आधिपत्य मित्याधि ★ पत्यम्। च मे। मे मन्युः। मन्युश्च। च मे। मे भामः। भामश्च। चमे। मेऽमः। अमश्च। च मे। मेऽम्भः। अम्भश्च। च मे। मे जेमा। जेमा च। च मे। मे महिमा। महिमा च। च मे। मे वरिमा। वरिमा च। च मे। मे प्रथिमा। प्रथिमा च। च मे। मे वर्ष्मा। वर्ष्मा च। च मे। मे द्राघुया। द्राघुया च। च मे। मे वृद्धम्। वृद्धञ्च। च मे। मे वृद्धिः। वृद्धिश्च। च मे। मे सत्यम्। सत्यञ्च। च मे। मे श्रद्धा। श्रद्धा च। श्रद्धेतिश्रत् ★ धा। च मे। मे जगत्। जगच्च। च मे॥ मे धनम्। धनञ्च। च मे। मे वशः। वशश्च। च मे। मे त्विषिः। त्विषिश्च। च मे। मे क्रीडा। क्रीडा च। च मे। मे मोदः। मोदश्च। चमे। मे जातम्। जातञ्च। चमे। मे जनिष्य माणम्। जनिष्य माणञ्च। च मे। मे सूक्तं। सूक्तञ्च। सूक्त मिति सु ★ उक्तम्। चमे। मे सुकृतम्। सुकृतञ्च। सुकृतमिति सु ★ कृतम्। च मे। मे वित्तम्। वित्तञ्च। च मे। मे वेद्यम्। वेद्यञ्च। च मे। मे भूतम्। भूतञ्च। च मे। मे भविष्यत्। भविष्यच्च। च मे। मे सुगम्। सुगञ्च। सुग मितिसु ★ गम्। च मे। मे सुपथम्। सुपथञ्च। सुपथ मिति सु ★ पथम्। च मे। म ऋद्धम्। ऋद्धञ्च। चमे। म ऋद्धिः। ऋद्धिश्च। च मे। मे क्लृप्तम्। क्लृप्तञ्च। च मे। मे क्लृप्तिः। क्लृप्तिश्च। च मे। मे मतिः। मतिश्च। च मे। मे सुमतिः। सुमतिश्च। सुमति रिति सु ★ मतिः। चमे। म इति मे॥

In Public domain. Digitization Muthulakshmi Research Academy

(३) शञ्च। चमे। मे मयः। मयश्च। चमे। मे प्रियम्। प्रियञ्च। च मे। मेऽनु कामः। अनुकामश्च। अनुकाम इत्यनु ★ कामः। च मे। मे कामः। कामश्च। च मे। मे सौमनसः। सौमनसश्च। च मे। मे भद्रम्। भद्रञ्च। चमे। मे श्रेयः। श्रेयश्च। चमे। मे वस्यः। वस्यश्च। चमे। मे यशः। यशश्च। चमे। मे भगः। भगश्च। चमे। मे द्रविणम्। द्रविणञ्च। चमे। मे यन्ता। यन्ता च। च मे। मे धर्त्ता। धर्त्ता च। च मे। मे क्षेमः। क्षेमश्च। च मे। मे धृतिः। धृतिश्च। च मे। मे विश्वम्। विश्वञ्च। चमे॥ मे महः। महश्च। च मे। मे संवित्। संविच्च। संविदिति सं ★ वित्। च मे। मे ज्ञात्रम्। ज्ञात्रञ्च। च मे। मे सूः। सूश्च। च मे। मे प्रसूः। प्रसूश्च। प्रसू रिति प्र ★ सूः। चमे। मे सीरम्। सीरञ्च। च मे। मे लयः। लयश्च। च मे। म ऋतम्। ऋतञ्च। च मे। मेऽमृतम्। अमृतञ्च। च मे। मेऽयक्ष्मम्। अयक्ष्मञ्च। च मे। मेऽनामयत्। अनामयच्च। च मे। मे जीवातुः। जीवातुश्च। च मे। मे दीर्घायुत्वम्। दीर्घायुत्वञ्च। दीर्घा युत्व मिति दीर्घायु ★ त्वम्। च मे। मेऽनमित्रम्। अनमित्रंच। चमे। मेऽभयम्। अभयञ्च। च मे। मे सुगम्। सुगञ्च। सुगमिति सु ★ गम्। च मे। मे शयनम्। शयनञ्च। च मे। मे सूषा। सूषा च। सूषेति सु ★ उषा। च मे। मे सुदिनम्। सुदिनञ्च। सुदिन मिति सु ★ दिनम्। चमे। म इति मे॥

(४) ऊर्क्च। च मे। मे सूनृता। सूनृता च। च मे। मे पयः। पयश्च। चमे। मे रसः। रसश्च। चमे। मे घृतम्। घृतञ्च। च मे। मे मधु। मधु च। चमे। मे सग्धिः। सग्धिश्च। च मे। मे सपीतिः।

In Public domain. Digitization Muthulakshmi Research Academy

सपीतिश्च ॥ सपीति रिति स ★ पीतिः । च मे । मे कृषिः । कृषिश्च । च मे । मे वृष्टिः । वृष्टिश्च । च मे । मे जैत्रम् । जैत्रञ्च । च मे । म औद्भिद्यम् । औद्भिद्यञ्च । औद्भिद्य मित्यौत् ★ भिद्यम् । च मे । मे रयिः । रयिश्च । च मे । मे रायः । रायश्च । च मे । मे पुष्टम् । पुष्टं च । च मे । मे पुष्टिः । पुष्टिश्च । चमे । मे विभु । विभु च । विभ्विति वि ★ भु । चमे ॥ मे प्रभु । प्रभु च । प्रभ्विति प्र ★ भु । च मे । मे बहु । बहु च । च मे । मे भूयः । भूयश्च । च मे । मे पूर्णम् । पूर्णञ्च । च मे । मे पूर्णतरम् । पूर्णतरञ्च । पूर्ण तर मिति पूर्ण ★ तरम् । च मे । मेऽक्षितिः । अक्षितिश्च । चमे । मे कूयवाः । कूयवाश्च । च मे । मेऽन्नम् । अन्नञ्च । च मे । मेऽक्षुत् । अक्षुच्च । च मे । मे व्रीहयः । व्रीहयश्च । च मे । मे यवाः । यवाश्च । च मे । मे माषाः । माषाश्च । च मे । मे तिलाः । तिलाश्च । च मे । मे मुद्गाः । मुद्गाश्च । च मे । मे खल्वाः । खल्वाश्च । च मे । मे गोधूमाः । गोधूमाश्च । च मे । मे मसुराः । मसुराश्च । च मे । मे प्रियङ्गवः । प्रियङ्गवश्च । च मे । मेऽणवः । अणवश्च । च मे । मे श्यामाकाः । श्यामाकाश्च । च मे । मे नीवाराः । नीवाराश्च । च मे । म इतिमे ॥

(५) अश्मा च । च मे । मे मृत्तिका । मृत्तिका च । च मे । मे गिरयः । गिरयश्च । च मे । मे पर्वताः । पर्वताश्च । च मे । मे सिकताः । सिकताश्च । चमे । मे वनस्पतयः । वनस्पतयश्च । च मे । मे हिरण्यं । हिरण्यञ्च । च मे । मेऽयः । अयश्च । च मे । मे सीसम् । सीसञ्च । च मे । मे त्रपुः । त्रपुश्च । च मे । मे श्यामम् । श्यामं च । च मे । मे लोहम् । लोहंच । च मे । मेऽग्निः । अग्निश्च । च मे । म

In Public domain. Digitization Muthulakshmi Research Academy

आपः। आपश्च। च मे। मे वीरुधः। वीरुधश्च। च मे। म ओषधयः। ओषधयश्च। च मे। मे कृष्ट पच्यम्। कृष्टपच्यञ्च। कृष्ट पच्य मिति कृष्ट ★ पच्यम्। चमे॥ मेऽकृष्ट पच्यम्। अकृष्ट पच्यञ्च। अकृष्टपच्य मित्य कृष्ट ★ पच्यम्। च मे। मे ग्राम्याः। ग्राम्याश्च। च मे। मे पशवः। पशव आरण्याः। आरण्याश्च। च यज्ञेन। यज्ञेन कल्पन्ताम्। कल्पन्तां वित्तम्। वित्तञ्च। च मे। मे वित्तिः। वित्तिश्च। चमे। मे भूतम्। भूतञ्च। च मे। मे भूतिः। भूतिश्च। च मे। मे वसु। वसु च। च मे। मे वसतिः। वसतिश्च। च मे। मे कर्म। कर्म च। च मे। मे शक्तिः। शक्तिश्च। च मे। मेऽर्थः। अर्थश्च। चमे। म एमः। एमश्च। चमे। म इतिः। इतिश्च। च मे। मे गतिः। गतिश्च। च मे। म इतिमे॥

(६) अग्निश्च। च मे। म इन्द्रः। इन्द्रश्च। चमे। मे सोमः। सोमश्च। चमे। म इन्द्रः। इन्द्रश्च। चमे। मे सविता। सविता च। च मे। म इन्द्रः। इन्द्रश्च। चमे। मे सरस्वती। सरस्वती च। च मे। म इन्द्रः। इन्द्रश्च। च मे। मे पूषा। पूषा च। चमे। म इन्द्रः। इन्द्रश्च। चमे। मे बृहस्पतिः। बृहस्पतिश्च। च मे। म इन्द्रः। इन्द्रश्च। च मे। मे मित्रः। मित्रश्च। च मे। म इन्द्रः। इन्द्रश्च। च मे। मे वरुणः। वरुणश्च। च मे। म इन्द्रः। इन्द्रश्च। च मे। मे त्वष्टा। त्वष्टा च। चमे॥ म इन्द्रः। इन्द्रश्च। चमे। मे धाता। धाता च। च मे। म इन्द्रः। इन्द्रश्च। च मे। मे विष्णुः। विष्णुश्च। चमे। म इन्द्रः। इन्द्रश्च। च मे। मेऽश्विनौ। अश्विनौ च। चमे। म इन्द्रः। इन्द्रश्च। चमे। मे मरुतः। मरुतश्च। चमे। म इन्द्रः। इन्द्रश्च। च मे। मे

In Public domain. Digitization Muthulakshmi Research Academy

विश्वे॑। विश्वे च। च मे। मे देवाः। देवाइन्द्रः। इन्द्रश्च। चमे। मे पृथिवी। पृथिवी च। च मे। म इन्द्रः। इन्द्रश्च। च मे। मेऽन्तरिक्षम्। अन्तरिक्षञ्च। च मे। म इन्द्रः। इन्द्रश्च। च मे। मे द्यौः। द्यौश्च। चमे। म इन्द्रः। इन्द्रश्च। च मे। मे दिशः। दिशश्च। च मे। म इन्द्रः। इन्द्रश्च। च मे। मे मूर्द्धा। मूर्द्धाच। च मे। म इन्द्रः। इन्द्रश्च। च मे। मे प्रजापतिः। प्रजापतिश्च। प्रजापति रिति प्रजा ★ पतिः। च मे। म इन्द्रः। इन्द्रश्च। च मे। म इति मे॥

(७) अꣳ शुश्च। च मे। मे रश्मिः। रश्मिश्च। च मे। मेऽदाभ्यः। अदाभ्यश्च। च मे। मेऽधिपतिः। अधिपतिश्च। अधिपति रित्यधि ★ पतिः। चमे। म उपाꣳशुः। उपाꣳशुश्च। उपाꣳ शु रित्युप ★ अꣳशुः। चमे। मेऽन्तर्यामः। अन्तर्यामश्च। अन्तर्याम इत्यन्तः ★ यामः। च मे। म ऐन्द्र वायवः। ऐन्द्र वायवश्च। ऐन्द्रवायव इत्यैन्द्र ★ वायवः। च मे। मे मैत्रावरुणः। मैत्रावरुणश्च। मैत्रा वरुण इति मैत्रा ★ वरुणः। च मे। म आश्विनः। आश्विनश्च। च मे। मे प्रति प्रस्थानः। प्रति प्रस्थानश्च। प्रतिप्रस्थान इति प्रति ★ प्रस्थानः। च मे। मे शुक्रः। शुक्रश्च। च मे। मे मन्थी। मन्थी च। च मे। म आग्रयणः। आग्रयणश्च। आग्रयण इत्या ★ ग्रयणः। च मे। मे वैश्वदेवः। वैश्व देवश्च। वैश्व देव इति वैश्व ★ देवः। च मे। मे ध्रुवः। ध्रुवश्च। च मे। मे वैश्वानरः। वैश्वानरश्च। च मे। म ऋतु ग्रहाः। ऋतुग्रहाश्च। ऋतुग्रहा इत्यृतु ★ ग्रहाः। च मे॥ मेऽतिग्राह्याः। अति ग्राह्याश्च। अति ग्राह्या

In Public domain. Digitization Muthulakshmi Research Academy

इत्यैति ★ ग्राह्याः। च मे। म ऐन्द्राग्नः। ऐन्द्राग्नश्च। ऐन्द्राग्न इत्यैन्द्र ★ अग्नः। च मे। मे वैश्वदेवः। वैश्व देवश्च। वैश्व देव इति वैश्व ★ देवः। च मे। मे मरुत्वतीयाः। मरुत्वतीयाश्च। च मे। मे माहेन्द्रः। माहेन्द्रश्च। माहेन्द्र इति माहा ★ इन्द्रः। च मे। म आदित्यः। आदित्यश्च। च मे। मे सावित्रः। सावित्रश्च। च मे। मे सारस्वतः। सारस्वतश्च। च मे। मे पौष्णः। पौष्णश्च। च मे। मे पात्नीवतः। पात्नीवतश्च। पात्नी वत इति पात्नी ★ वतः। च मे। मे हारियोजनः। हारियोजनश्च। हारियोजन इति हारि ★ योजनः। चमे। म इति मे॥

(८) इध्मश्च। च मे। मे बर्हिः। बर्हिश्च। च मे। मे वेदिः। वेदिश्च। च मे। मे धिष्णियाः। धिष्णियाश्च। च मे। मे स्रुचः। स्रुचश्च। च मे। मे चमसाः। चमसाश्च। च मे। मे ग्रावाणः। ग्रावाणश्च। च मे। मे स्वरवः। स्वरवश्च। च मे। म उपरवाः। उपरवाश्च। उपरवा इत्युप ★ रवाः। च मे। मेऽधिषवणे। अधिषवणे च। अधिषवणे इत्यधि ★ सवने। च मे। मे द्रोण कलशः। द्रोण कलशश्च। द्रोण कलश इति द्रोण ★ कलशः। च मे। मे वायव्यानि। वायव्यानि च। च मे। मे पूतभृत्। पूतभृच्च। पूतभृ दिति पूत ★ भृत्। च मे। म आधवनीयः। आधवनीयश्च। आधवनीय इत्या ★ धवनीयः। च मे। म आग्नीध्रम्। आग्नीध्रञ्च। आग्नीध्र मित्याग्नि ★ इध्रम्। च मे। मे हविर्द्धानम्। हविर्द्धानञ्च। हविर्द्धान मिति हविः ★ धानम्। च मे। मे गृहाः। गृहाश्च। च मे। मे सदः। सदश्च। च मे। मे

In Public domain. Digitization Muthulakshmi Research Academy

पुरोडाशाः। पुरोडाशाश्च। च मे। मे पचताः। पचताश्च। च मे। मेऽवभृथः। अवभृथश्च। अवभृथ इत्यव ★ भृथः। च मे। मे स्वगाकारः। स्वगाकारश्च। स्वगाकार इति स्वगा ★ कारः। च मे। म इति मे॥

(९) अग्निश्च। च मे। मे घर्मः। घर्मश्च। च मे। मेऽर्क्कः। अर्क्कश्च। च मे। मे सूर्यः। सूर्यश्च। च मे। मे प्राणः। प्राणश्च। प्राण इति प्र ★ अनः। च मे। मेऽश्वमेधः। अश्वमेधश्च। अश्वमेध इत्यश्व ★ मेधः। च मे। मे पृथिवी। पृथिवी च। च मे। मेऽदितिः। अदितिश्च। च मे। मे दितिः। दितिश्च। च मे। मे द्यौः। द्यौश्च। च मे। मे शक्वरीः। शक्वरी रङ्गुलयः। अङ्गुलयो दिशः। दिशश्च। च मे। मे यज्ञेन। यज्ञेन कल्पन्ताम्। कल्पन्ता मृक्। ऋक्च। च मे। मे साम। साम च। च मे। मे स्तोमः। स्तोमश्च। च मे। मे यजुः। यजुश्च। च मे। मे दीक्षा। दीक्षा च। च मे। मे तपः। तपश्च। च मे। म ऋतुः। ऋतुश्च। च मे। मे व्रतम्। व्रतञ्च। च मे। मेऽहोरात्रयोः। अहोरात्रयोर्वृष्ट्या। अहो रात्रयो रित्यहः ★ रात्रयोः। वृष्ट्या बृहद्रथन्तरे। बृहद्रथन्तरे च। बृहद्रथन्तरे इति बृहत् ★ रथन्तरे। च मे। मे यज्ञेन। यज्ञेन कल्पेताम्। कल्पेता मिति कल्पेताम्॥

(१०) गर्भाश्च। च मे। मे वथ्साः। वथ्साश्च। च मे। मे त्र्यविः। त्र्यविश्च। त्र्यविरिति त्रि ★ अविः। च मे। मे त्र्यवी। त्र्यवी च। त्र्यवीतित्रि ★ अवी। चमे। मे दित्यवाट्। दित्यवाट् च। दित्यवाडितिदित्य ★ वाट्। च मे। मे दित्यौही। दित्यौ ही च। च मे। मे पञ्चाविः। पञ्चाविश्च। पञ्चावि रिति पञ्च ★ अविः। च मे।

In Public domain. Digitization Muthulakshmi Research Academy

मे पञ्चावी। पञ्चावी चं। पञ्चावीतिं पञ्च ★ अवी। च मे। मे त्रिवथ्सः। त्रिवथ्सश्चं। त्रिवथ्स इतिं त्रि ★ वथ्सः। च मे। मे त्रिवथ्सा। त्रिवथ्सा चं। त्रिवथ्सेतिं त्रि ★ वथ्सा। च मे। मे तुर्यवाट्। तुर्यवाट् चं। तुर्यवाडितितुर्य ★ वाट्। च मे। मे तुर्यौही। तुर्यौही चं। च मे। मे पष्ठवात्। पष्ठवाच्चं। पष्ठवा दितिं पष्ठ ★ वात्। च मे। मे पष्ठौही। पष्ठौही चं। च मे। म उक्षा। उक्षा चं। च मे। मे वशा। वशा चं। च मे। म ऋषभः। ऋषभ श्चं। च मे॥ मे वेहत्। वेह च्चं। च मे। मेऽनड्वान्। अनड्वाञ्चं। च मे। मे धेनुः। धेनुश्चं। च मे। म आयुः। आयुर्यज्ञेनं। यज्ञेनं कल्पताम्। कल्पतां प्राणः। प्राणो यज्ञेनं। प्राण इतिं प्र ★ अनः। यज्ञेनं कल्पताम्। कल्पता मपानः। अपानो यज्ञेनं। अपान इत्यंप ★ अनः। यज्ञेनं कल्पताम्। कल्पतां व्यानः। व्यानो यज्ञेनं। व्यान इतिं वि ★ अनः। यज्ञेनं कल्पताम्। कल्पतां चक्षुः। चक्षुर्यज्ञेनं। यज्ञेनं कल्पताम्। कल्पताꣳ श्रोत्रꣳम्। श्रोत्रं यज्ञेनं। यज्ञेनं कल्पताम्। कल्पतां मनः। मनोयज्ञेनं। यज्ञेनं कल्पताम्। कल्पतां वाक्। वाग्यज्ञेनं। यज्ञेनं कल्पताम्। कल्पता मात्मा। आत्मा यज्ञेनं। यज्ञेनं कल्पताम्। कल्पतां यज्ञः। यज्ञो यज्ञेनं। यज्ञेनं कल्पताम्। कल्पता मितिं कल्पताम्॥

(११) एकां च। च मे। मे तिस्रः। तिस्रश्चं। च मे। मे पञ्चं। पञ्चं च। च मे। मे सप्त। सप्त चं। च मे। मे नवं। नवं च। च मे। म एकांदश। एकांदश च। च मे। मे त्रयोंदश। त्रयोंदश च।

In Public domain. Digitization Muthulakshmi Research Academy

त्रयोदशेति त्रयः ★ दश। च मे। मे पञ्चदश। पञ्चदश च।
पञ्चदशेति पञ्च ★ दश। च मे। मे सप्त दश। सप्तदश च।
सप्तदशेति सप्त ★ दश। च मे। मे नवदश। नवदश च।
नवदशेति नव ★ दश। च मे। म एकविंशतिः।
एकविंशतिश्च। एकविंशति रित्येक ★ विंशतिः। च मे। मे
त्रयोविंशतिः। त्रयोविंशतिश्च। त्रयोविंशति रिति त्रयः ★
विंशतिः। च मे। मे पञ्चविंशतिः। पञ्चविंशतिश्च।
पञ्चविंशति रिति पञ्च ★ विंशतिः। च मे। मे सप्त विंशतिः।
सप्तविंशतिश्च। सप्तविंशति रिति सप्त ★ विंशतिः। च मे।
मे नव विंशतिः। नवविंशतिश्च। नवविंशति रिति नव ★
विंशतिः। च मे। म एक त्रिंशत्। एक त्रिंशच्च। एक
त्रिंशदित्येक ★ त्रिंशत्। च मे। मे त्रयस्त्रिंशत्।
त्रयस्त्रिंशच्च। त्रयस्त्रिंशदि ति त्रयः ★ त्रिं शत्। च मे॥ मे
चतस्रः। चतस्रश्च। च मे। मेऽष्टौ। अष्टौ च। च मे। मे द्वादश।
द्वादश च। च मे। मे षोडश। षोडश च। चमे। मे विंशतिः।
विंशति श्च। च मे। मे चतुर्विंशतिः। चतुर्विंशति श्च।
चतुर्विंशति रिति चतुः ★ विंशतिः। च मे। मेऽष्टाविंशतिः।
अष्टा विंशतिश्च। अष्टा विंशति रित्यष्टा ★ विंशतिः। च
मे। मे द्वात्रिंशत्। द्वात्रिंशच्च। च मे। मे षट्त्रिंशत्।
षट्त्रिंशच्च। षट् त्रिंशदिति षट् ★ त्रिंशत्। च मे। मे
चत्वारिंशत्। चत्वारिंशच्च। च मे। मे चतु- श्चत्वारिंशत्।

In Public domain. Digitization Muthulakshmi Research Academy

चतुश्चत्वारिꣳशच्च। चतुश्चत्वारिꣳश दिति चतुः ★ चत्वारिꣳशत्। च मे। मेऽष्टा चत्वारिꣳशत्। अष्टा चत्वारिꣳशच्च। अष्टा चत्वारिꣳश दित्यष्टा ★ चत्वारिꣳशत्। च मे। मे वाजः। वाजश्च। च प्रसवः। प्रसवश्च। प्रसव इति प्र ★ सवः। चाऽपिजः। अपिजश्च। अपिज इत्यपि ★ जः। च क्रतुः। क्रतुश्च। च सुवः। सुवश्च। च मूर्धा। मूर्धा च। च व्यश्नियः। व्यश्नियश्च। व्यश्निय इति वि ★ अश्नियः। चान्त्यायनः। आन्त्यायन श्च। चान्त्यः। अन्त्यश्च। च भौवनः। भौवन श्च। च भुवनः। भुवनश्च। चाऽधिपतिः। अधिपति श्च। अधिपति रित्यधि ★ पतिः। चेति च॥

ओं शान्तिश्शान्तिश्शान्तिः॥

इडा देवहूः। देवहूर्मनुः। देवहूरिति देव ★ हूः। मनुर्यज्ञनीः। यज्ञनीर्बृहस्पतिः। यज्ञनी रिति यज्ञ ★ नीः। बृहस्पति रुक्था मदानि। उक्था मदानि शꣳसिषत्। उक्था मदानी त्युक्थ ★ मदानि। शꣳसिषद् विश्वे॑। विश्वेदेवाः। देवास्सूक्त वाचः। सूक्त वाचः पृथिवि। सूक्तवाच इति सूक्त ★ वाचः। पृथिवि मातः। मात र्मा। मा मा॑। मा हिꣳसीः। हिꣳसी र्मधु। मधु मनिष्ये। मनिष्ये मधु। मधु जनिष्ये। जनिष्ये मधु। मधु वक्ष्यामि। वक्ष्यामि मधु। मधु वदिष्यामि। वदिष्यामि मधुमतीम्। मधुमतीं देवेभ्यः। मधुमती मिति मधु ★ मतीम्। देवेभ्यो वाच॑म्। वाचमुद्यासम्।

In Public domain. Digitization Muthulakshmi Research Academy

उद्यासꣳशुश्रूषेण्याम्। शुश्रुषेण्या मनुष्येभ्यः। मनुष्येभ्य स्तम्। तं मा। मा देवाः। देवा अवन्तु। अवन्तु शोभायै। शोभायै पितरः। पितरोऽनु। अनुमदन्तु। मदन्त्विति मदन्तु॥

ओं शान्तिश्शान्तिश्शान्तिः॥

॥ हारती उपचार मन्त्राः ॥

सांग्र हुण्येष्ट्यायजते। इमां जनता ꣳ सङ्गृह्णानीति। द्वादशारत्नी रशना भवति। द्वादशमासाः संवथ्सरः। संवथ्सरमेवा वरुन्धे। मौञ्जी भवति। ऊर्ग्वैमुंजाः। ऊर्जमेवा वरुन्धे। चित्रानक्षत्रं भवति। चित्रं वाएतत्कर्म। यदश्व मेधः समृद्ध्यै॥

॥ अलंकार दीपः ॥

सप्रथ सभां मै गोपाय। ये च सभ्यास्सभासदः। तानिन्द्रियावतः कुरु। सर्वमायुरुपासताम्। अहेबुध्निय मन्त्रं मे गोपाय। यमृषयस्त्रैविदा विदुः। ऋचस्सामानि यजूꣳषि। सा हि श्रीरमृता सताम्॥

सद्योजातं प्रपद्यामि सद्योजाताय वै नमो नमः। भवे भवे नातिभवे भवस्व माम्। भवोद्भवाय नमः॥

वामदेवाय नमो ज्येष्ठाय नमश्श्रेष्ठाय नमो रुद्राय नमः कालाय नमः कलविकरणाय नमो बलविकरणाय नमो बलाय नमो बलप्रमथनाय नमस्सर्वभूतदमनाय नमो मनोन्मनाय नमः॥

अघोरेभ्योऽथ घोरेभ्यो घोरघोरतरेभ्यः। सर्वेभ्य-स्सर्वशर्वेभ्यो नमस्ते अस्तु रुद्ररूपेभ्यः॥

In Public domain. Digitization Muthulakshmi Research Academy

तत्पुरुषाय विद्महे महादेवाय धीमहि। तन्नो रुद्रः प्रचोदयात्॥

ईशान स्सर्वविद्याना मीश्वर स्सर्वभूतानां ब्रह्माऽधिपति ब्रह्मणोधिपति ब्रह्मा शिवो मे अस्तु सदाशिवोम्॥

हिरण्यपात्रम् मधोः पूर्णं ददाति। मधव्यो सानीति। एकधा ब्रह्मण उपहरति। एकधैव यजमान आयुस्तेजो दधाति॥

सोमो वा एतस्य राज्यमादत्ते। यो राजासन् राज्योवा सोमेन यजते। देवसुवामेतानि हवीꣳषि भवन्ति। एतावन्तो वै देवानाꣳसवाः। त एवास्मै सवान् प्रयच्छन्ति। त एनं पुनः सुवन्ते राज्याय। देवसू राजा भवति (कर्पूर नीराजनं/आज्य दीपं दर्शयामि)।

योऽपां पुष्पं वेद। पुष्पवान् प्रजावान् पशुमान् भवति। चन्द्रमा वा अपां पुष्पम्। पुष्पवान् प्रजावान् पशुमान् भवति। य एवं वेद। योऽपामायतनं वेद। आयतनवान् भवति।

यो देवानां प्रथमं पुरस्तात् विश्वाधियो रुद्रो महर्षिः। हिरण्यगर्भं पश्यत जायमान ꣳ सनोदेव श्शुभया स्मृत्या स्संयुनक्तु॥

यस्मात्परन्नापर मस्ति किञ्चिद्यस्मान्नाणीयो नज्यायोऽस्ति कश्चित्। वृक्ष इव स्तब्धो दिवितिष्ठत्येक स्तेनेदं पूर्णं पुरुषेण सर्वम्॥

न कर्मणा न प्रजया धनेन त्यागे नैके अमृतत्व-मानशुः। परेण नाकं निहितं गुहायां विभ्राजदेतद्यतयो विशन्ति। वेदान्त विज्ञान सुनिश्चितार्थास्सन्यास योगाद्यतयश्शुद्धसत्त्वाः। ते

In Public domain. Digitization Muthulakshmi Research Academy

ब्रह्मलोकेतु परान्तकाले परामृतात्परिमुच्यन्ति सर्वे। दह्रं विपापं परमेश्मभूतं यत्पुण्डरीकं पुरमध्यसग्गस्थम्। तत्रापि दह्रं गगनं विशोकस्तस्मिन् यदन्तस्तदुपासितव्यम्। यो वेदादौ स्वरः प्रोक्तो वेदान्ते च प्रतिष्ठितः। तस्य प्रकृति लीनस्य यः परस्स महेश्वरः॥

सिद्धि बुद्धि अंबा समेत कर्पक विनायक स्वामिने नमः, वेदोक्त मन्त्र पुष्पम् समर्पयामि॥ स्वर्ण पुष्पम् समर्पयामि।

हरिः ओं। अग्निमीळे पुरोहितं यज्ञस्य देवमृत्विजम्। होतारं रत्नधातमम्॥ हरिः ओम्॥

हरिः ओम्। इषे त्वोर्जे त्वा वायवस्थोऽपायवस्थ देवो वस्सविता प्रार्पयतु श्रेष्ठतमाय कर्मणे॥ हरिः ओम्॥

हरिः ओम्। अग्न आयाहि वीतये गृणानो हव्यदातये। निहोता सत्सि बर्हिषि॥ हरिः ओम्॥

हरिः ओम्। शन्नो देवीरभिष्टय आपो भवन्तु पीतये। शँय्योरभिस्स्रवन्तु नः॥ हरिः ओम्॥

अथातः दर्श पूर्णमासौ व्याख्या स्यामः। प्रातः (सायम्) अग्निहोत्रं हुत्वा। अन्यमा हवनीयं प्रणीय। अग्नीनन्वा दधाति। नगतश्रि योऽन्य मग्निम् प्रणयति॥

परित्राणाय साधूनां विनाशाय च दुष्कृताम्।
धर्म संस्थापनार्थाय संभवामि युगे युगे॥

स्वस्ति प्रजाभ्यः परिपालयन्तां न्याय्येन मार्गेण महीं महीशाः। गो ब्राह्मणेभ्यः शुभमस्तु नित्यं लोकाः समस्ताः सुखिनो भवन्तु॥

काले वर्षतु पर्जन्यः पृथिवी सस्यशालिनी। देशोऽयं क्षोभरहितो ब्राह्मणाः सन्तुनिर्भयाः॥

In Public domain. Digitization Muthulakshmi Research Academy

अपुत्राः पुत्रिणस्सन्तु पुत्रिणस्सन्तु पौत्रिणः। अधनास्स-धनास्सन्तु जीवन्तु शरदां शतम्॥

ओं दूरमस्मच्छत्रवो यन्तु भीताः। तदिन्द्राग्नी कृणुतां तद्विशाखे। तन्नो देवा अनुमदन्तु यज्ञम्। पश्चात् पुरस्तादभयन्नो अस्तु॥

राजाधि राजाय प्रसह्य साहिने। नमो वयं वैश्रवणाय कुर्महे। स मे कामान् काम कामाय मह्यम्। कामेश्वरो वैश्रवणो ददातु। कुबेराय वैश्रवणाय। महाराजाय नमः॥

वायुस्ताः अग्रे प्रमुमोक्तु देवः प्रजापतिः प्रजया संविदानः॥

चन्द्रमा मनसो जातः। चक्षोः सूर्यो अजायत। मुखा-दिन्द्रश्चाग्निश्च। प्राणाद्वायुरजायत॥

यज्ञेन यज्ञमयजन्त देवाः। तानि धर्माणि प्रथमान्यासन्। ते ह नाकं महिमानः सचन्ते। यत्र पूर्वे साध्यास्सन्ति देवाः॥

केतुङ्कृण्वन्न केतवे पेशो मर्या अपेशसे। समुष-द्भिरजायथाः। ब्रह्मा देवानां पदवीः कवीनामृषिर्विप्राणां महिषो मृगाणाम्।

राजाधि राजाय प्रसह्य साहिने। नमो वयं वैश्रवणाय कुर्महे। स मे कामान् काम कामाय मह्यम्। कामेश्वरो वैश्रवणो ददातु। कुबेराय वैश्रवणाय। महाराजाय नमः॥

सिद्धि बुद्धि अंबा समेत कल्पक विनायक स्वामिने नमः कर्पूर नीराजनं/आज्य दीपं दर्शयामि।

In Public domain. Digitization Muthulakshmi Research Academy

तत्पुरुषाय विद्महे वक्रतुण्डाय धीमहि।

तन्नो दन्तिः प्रचोदयात्॥

नमो व्रातपतये नमो गणपतये नमः प्रमथपतये नमस्तेऽस्तु लम्बोदरायैकदन्ताय विघ्ननाशिने शिवसुताय श्री वरदमूर्तये नमो नमः॥

श्री कामः शान्तिकामः पुष्टिकामः प्रजाकामो मेधाकाम आयुष्यकामः। आरोग्यकामः अन्नाद्य कामो वा एवं कुर्वन् क्रतु सहस्रफलमवाप्नोतीत्याह भगवान् बोधायनः। एवं यः कुरुते नित्यं सर्वपापैः प्रमुच्यते। सर्वान्कामनवाप्नोति शिव सायुज्य माप्नुयात्॥

॥ क्षमा प्रार्थना ॥

यदक्षर पदभ्रष्टं मात्रा हीनं तु यद्भवेत्। तत् सर्वं क्षम्यतां देव नारायण नमोऽस्तुते॥१॥

विसर्ग बिन्दु मात्राणि पदपादाक्षराणि च। न्यूनानि चातिरिक्तानि क्षमस्व करुणानिधे॥२॥

मन्त्रहीनं क्रियाहीनं भक्तिहीनं सुरेश्वर। यत्पूजितं मया देव परिपूर्णं तदस्तु ते॥३॥

कायेन वाचा मनसेन्द्रियैर्वा बुद्ध्यात्मना वा प्रकृतेः स्वभावात्। करोमि यद्यत् सकलं परस्मै नारायणायेति समर्पयामि॥४॥

करचरण कृतं वाक्कायजं कर्मजं वा, श्रवण नयनजं वा मानसं वाऽपराधम्। विहितमविहितं वा सर्वमेतत् क्षमस्व, जय जय करुणाब्धे श्री महादेव शम्भो॥५॥

In Public domain. Digitization Muthulakshmi Research Academy

श्रीरुद्रं न जानामि, न जानामि चमकम्। सूक्तानि न जानामि, न जानामि स्तोत्राणि। आवाहनं न जानामि, न जानामि विसर्जनम्। पूजा विधिं न जानामि, क्षमस्व परमेश्वर ॥६॥

ॐ शान्तिः शान्तिः शान्तिः ॥

॥ बिल्वाष्टोत्तरशतस्तोत्रम् ॥

त्रिदलं त्रिगुणाकारं त्रिनेत्रं च त्रियायुषम्।
त्रिजन्मपापसंहारं एकबिल्वं शिवार्पणम्॥१॥
त्रिशाखैर्बिल्वपत्रैश्च अच्छिद्रैः कोमलैः शुभैः।
तव पूजां करिष्यामि एकबिल्वं शिवार्पणम्॥२॥
सर्वत्रैलोक्यकर्तारं सर्वत्रैलोक्यपालकम्।
सर्वत्रैलोक्यहर्तारं एकबिल्वं शिवार्पणम्॥३॥
नागाधिराजवलयं नागहारेणभूषितम्।
नागकुण्डलसंयुक्तं एकबिल्वं शिवार्पणम्॥४॥
अक्षमालाधरं रुद्रं पार्वतीप्रियवल्लभम्।
चन्द्रशेखरमीशानं एकबिल्वं शिवार्पणम्॥५॥
त्रिलोचनं दशभुजं दुर्गादेहार्धधारिणम्।
विभूतिचर्चितं देवं एकबिल्वं शिवार्पणम्॥६॥
त्रिशूलधारिणं देवं नागाभरणसुन्दरम्।
चन्द्रशेखरमीशानं एकबिल्वं शिवार्पणम्॥७॥
गङ्गाधरमुमानाथं फणिमण्डलमण्डितम्।
कालकालं गिरीशञ्च एकबिल्वं शिवार्पणम्॥८॥
शुद्धस्फटिकसंकाशं शितिकण्ठं कृपानिधिम्।
सर्वेश्वरं सदाशान्तं एकबिल्वं शिवार्पणम्॥९॥

In Public domain. Digitization Muthulakshmi Research Academy

सच्चिदानन्दरूपं च परमानन्दमयं शिवम्।
वागीश्वरं चिदाकाशं एकबिल्वं शिवार्पणम्॥१०॥
शिपिविष्टं सहस्राक्षं दुन्दुभ्यञ्च निषङ्गिणम्।
हिरण्यबाहुं सेनान्यं एकबिल्वं शिवार्पणम्॥११॥
करुणं वामनं तारं वास्तव्यं शैववास्तुपम्।
ज्येष्ठं कनिष्ठं वैशालं एकबिल्वं शिवार्पणम्॥१२॥
हरिकेशं वनाधीशं उच्चैर्घोषं सनातनम्।
अघोररूपकं कुम्भं एकबिल्वं शिवार्पणम्॥१३॥
पूर्वजापरजं याम्यं सूक्ष्मतस्करनायकम्।
नीलकण्ठं जघन्यञ्च एकबिल्वं शिवार्पणम्॥१४॥
सुराश्रयं विषहरं वर्मिणञ्च वरूथिनम्।
महासेनं महावीरं एकबिल्वं शिवार्पणम्॥१५॥
कुमारं कुशलं कूप्यं वदान्यञ्च महारथम्।
मायावार्यञ्च दिव्यञ्च एकबिल्वं शिवार्पणम्॥१६॥
दशकर्णं ललाटाक्षं पञ्चवक्त्रं सदाशिवम्।
अशेषपापसंहारं एकबिल्वं शिवार्पणम्॥१७॥
नीलकण्ठं जगद्वन्द्यं दीननाथं महेश्वरम्।
महापापहरं शम्भुं एकबिल्वं शिवार्पणम्॥१८॥
चूडामणीकृतविधुं वलयीकृतवासुकिम्।
कैलासनिलयं भौमं एकबिल्वं शिवार्पणम्॥१९॥
कर्पूरकुन्दधवलं नरकार्णवतारकम्।
करुणामृतसिन्धुञ्च एकबिल्वं शिवार्पणम्॥२०॥
महादेवं महात्मानं भुजङ्गाधिपकङ्कणम्।
महापापहरं देवं एकबिल्वं शिवार्पणम्॥२१॥
भूतेशं खण्डपरशुं वामदेवं पिनाकिनम्।
वामे शक्तिधरं श्रेष्ठं एकबिल्वं शिवार्पणम्॥२२॥

In Public domain. Digitization Muthulakshmi Research Academy

फाले क्षणं विरूपाक्षं श्रीकण्ठं भक्तवत्सलम्।
नीललोहितखट्वाङ्गं एकबिल्वं शिवार्पणम्॥२३॥
कैलासवासिनं भीमं कठोरं त्रिपुरान्तकम्।
वृषाङ्कं वृषभारूढं एकबिल्वं शिवार्पणम्॥२४॥
सामप्रियं स्वरमयं भस्मोद्धूलितविग्रहम्।
मृत्युञ्जयं लोकनाथं एकबिल्वं शिवार्पणम्॥२५॥
दारिद्र्यदुःखहरणं रविचन्द्रानलेक्षणम्।
मृगपाणिं चन्द्रमौलिं एकबिल्वं शिवार्पणम्॥२६॥
सर्वलोकमयाकारं सर्वलोकैकसाक्षिणम्।
निर्मलं निर्गुणाकारं एकबिल्वं शिवार्पणम्॥२७॥
सर्वतत्त्वात्मकं साम्बं सर्वतत्त्वविदूरकम्।
सर्वतत्त्वविरूपञ्च एकबिल्वं शिवार्पणम्॥२८॥
सर्वलोकगुरुं स्थाणुं सर्वलोकवरप्रदम्।
सर्वलोकस्य नेत्रञ्च एकबिल्वं शिवार्पणम्॥२९॥
मन्मथोद्धारणं शैवं भवं भर्गं परात्मकम्।
कमलाप्रियपूज्यञ्च एकबिल्वं शिवार्पणम्॥३०॥
तेजोमयं महाभीमं स्मरभस्मविलेपनम्।
भवरोगविनाशञ्च एकबिल्वं शिवार्पणम्॥३१॥
स्वर्गापवर्गफलदं रघुनाथवरप्रदम्।
नगराजसुताकान्तं एकबिल्वं शिवार्पणम्॥३२॥
मञ्जीरपादयुगलं शुभलक्षणलक्षितम्।
फणिराजविराजञ्च एकबिल्वं शिवार्पणम्॥३३॥
निरामयं निराधारं निस्सङ्गं निष्प्रपञ्चकम्।
तेजोरूपं महारौद्रं एकबिल्वं शिवार्पणम्॥३४॥
चित्राम्बरं चिदाभासं वृषभेश्वरवाहनम्।
नीलग्रीवं चतुर्वक्त्रं एकबिल्वं शिवार्पणम्॥३५॥

In Public domain. Digitization Muthulakshmi Research Academy

सर्वलोकैकपितरं सर्वलोकैकमातरम्।
सर्वलोकैकनाथञ्च एकबिल्वं शिवार्पणम्॥३६॥
रत्नकञ्चुकरत्नेशं रत्नकुण्डलमण्डितम्।
नवरत्नकिरीटञ्च एकबिल्वं शिवार्पणम्॥३७॥
दिव्यरत्नाङ्गुलीकर्णरत्नाभरणभूषितम्।
नानारत्नं मणिमयं एकबिल्वं शिवार्पणम्॥३८॥
रत्नाङ्गुलीयविलसत्करशाखाधिकप्रभम्।
भक्तमानसगेहञ्च एकबिल्वं शिवार्पणम्॥३९॥
वामाङ्गभागविलसदम्बिकावीक्षणप्रियम्।
पुण्डरीकनिभाक्षञ्च एकबिल्वं शिवार्पणम्॥४०॥
सम्पूर्णकामदं सौख्यं भक्तेष्टफलपूरकम्।
सौभाग्यदं हितकरं एकबिल्वं शिवार्पणम्॥४१॥
नानाशास्त्रगुणोपेतं स्फुरन्मङ्गलविग्रहम्।
विद्याविभेदरहितं एकबिल्वं शिवार्पणम्॥४२॥
अप्रमेयगुणाधारं वेदकृद्रूपविग्रहम्।
धर्माधर्मप्रवृत्तञ्च एकबिल्वं शिवार्पणम्॥४३॥
गौरीविलाससदनं जीवजीवपितामहम्।
कल्पान्तभैरवं शुभ्रं एकबिल्वं शिवार्पणम्॥४४॥
सुखदं सुखनाशञ्च दुखदं दुःखनाशनम्।
दुःखावधानं भद्रञ्च एकबिल्वं शिवार्पणम्॥४५॥
सुखरूपं रूपनाशं सर्वधर्मफलप्रदम्।
अतीन्द्रियं महामायं एकबिल्वं शिवार्पणम्॥४६॥
सर्वपक्षिमृगाकारं सर्वपक्षिमृगाधिपम्।
सर्वपक्षिमृगाधारं एकबिल्वं शिवार्पणम्॥४७॥
जीवाध्यक्षं जीववर्यं जीवजीवनरक्षकम्।
जीवकृज्जीवहरणं एकबिल्वं शिवार्पणम्॥४८॥

In Public domain. Digitization Muthulakshmi Research Academy

विश्वात्मानं विश्ववन्द्यं वज्रात्मवज्रहस्तकम्।
वज्रेशं वज्रभूषञ्च एकबिल्वं शिवार्पणम्॥४९॥
गणाधिपं गणाध्यक्षं प्रलयानलनाशकम्।
दिगम्बरं क्षोभनाशं एकबिल्वं शिवार्पणम्॥५०॥
त्रयम्बकं मृडं शूलमरिष्टवर्गनाशकम्।
जितेन्द्रियं वीरभद्रं एकबिल्वं शिवार्पणम्॥५१॥
कुन्देन्दुशंखधवलं भगनेत्रभिदुज्ज्वलम्।
कालाग्निरुद्रं सर्वज्ञं एकबिल्वं शिवार्पणम्॥५२॥
कम्बुग्रीवं कम्बुकण्ठं धैर्यदं धैर्यवर्धकम्।
शार्दूलचर्मवसनं एकबिल्वं शिवार्पणम्॥५३॥
जगदुत्पत्तिहेतुञ्च जगत्प्रलयकारणम्।
पूर्णानन्दस्वरूपञ्च एकबिल्वं शिवार्पणम्॥५४॥
स्वर्णकेशं महत्तेजः पुण्यश्रवणकीर्तनम्।
ब्रह्माण्डनायकं तारं एकबिल्वं शिवार्पणम्॥५५॥
मन्दारमूलनिलयं मन्दारकुसुमप्रियम्।
वृन्दारकप्रियतरं एकबिल्वं शिवार्पणम्॥५६॥
महेन्द्रियं महाबाहुं विश्वासपरिपूरकम्।
सुलभासुलभं लभ्यं एकबिल्वं शिवार्पणम्॥५७॥
बीजाधारं बीजरूपं निर्बीजं बीजवृद्धिदम्।
परेशं बीज नाशञ्च एकबिल्वं शिवार्पणम्॥५८॥
युगाधारं युगाधीशं युगकृद्युगनाशकम्।
युगेशं युगनाशञ्च एकबिल्वं शिवार्पणम्॥५९॥
धूर्जटिं पिङ्गलजटं जटामण्डलमण्डितम्।
कर्पूरगौरं गौरीशं एकबिल्वं शिवार्पणम्॥६०॥
सुरावासं जनावासं योगीशं योगिपुंगवम्।
योगदं योगिनां सिम्हं एकबिल्वं शिवार्पणम्॥६१॥

In Public domain. Digitization Muthulakshmi Research Academy

उत्तमानुत्तमं तत्वमन्धकासुरसूदनम्।
भक्तकल्पद्रुमं स्तव्यं एकबिल्वं शिवार्पणम्॥६२॥
विचित्रमाल्यवसनं दिव्यचन्दनचर्चितम्।
विष्णुब्रह्मादिवन्द्यञ्च एकबिल्वं शिवार्पणम्॥६३॥
कुमारपितरं देवं सितचन्द्रकलानिधिम्।
ब्रह्मशत्रुं जगन्मित्रं एकबिल्वं शिवार्पणम्॥६४॥
लावण्यमधुराकारं करुणारसवारिधिम्।
भ्रुवोर्मध्ये सहस्त्रार्चिं एकबिल्वं शिवार्पणम्॥६५॥
जटाधरं पावकाक्षमृक्षेशं भुवनाश्रयम्।
कामदं सर्वदागम्यं एकबिल्वं शिवार्पणम्॥६६॥
शिवं शान्तमुमानाथं महाध्यानपरायणम्।
ज्ञानप्रदं कृत्तिवासं एकबिल्वं शिवार्पणम्॥६७॥
वासुक्युरगहारञ्च लोकानुग्रहकारणम्।
ज्ञानप्रदं कृत्तिधरं एकबिल्वं शिवार्पणम्॥६८॥
शशाङ्कधारिणं भर्गं सर्वलोकैकशङ्करम्।
शुद्धञ्च शाश्वतं नित्यं एकबिल्वं शिवार्पणम्॥६९॥
शरणागतदीनार्तपरित्राणपरायणम्।
गम्भीरञ्च वषट्कारं एकबिल्वं शिवार्पणम्॥७०॥
भोक्तारं भोजनं भोज्यं जेतारं जितमानसम्।
करणं कारणं जिष्णुं एकबिल्वं शिवार्पणम्॥७१॥
क्षेत्रज्ञं क्षेत्रपालञ्च परार्थैकप्रयोजनम्।
व्योमकेशं भीमवेषं एकबिल्वं शिवार्पणम्॥७२॥
भाविजं तरुणोपेतं क्षेमदिष्ट्यमशासकम्।
हिरण्यगर्भं हेमाङ्गं एकबिल्वं शिवार्पणम्॥७३॥
दक्षञ्चामुण्डाजनकं मोक्षदं मोक्षदायकम्।
हिरण्यदं हेमरूपं एकबिल्वं शिवार्पणम्॥७४॥

In Public domain. Digitization Muthulakshmi Research Academy

महाश्मशाननिलयं प्रसन्नस्फटिकप्रभम्।
वेदाश्वं वेदरूपञ्च एकबिल्वं शिवार्पणम्॥७५॥
स्थिरं स्वधर्ममानाभं ब्रह्मण्यं चाश्रयं विभुम्।
जगन्निवासं प्रथमं एकबिल्वं शिवार्पणम्॥७६॥
रुद्राक्षमालाभरणं रुद्राक्षप्रियवत्सलम्।
रुद्राक्षभक्तसंस्तव्यं एकबिल्वं शिवार्पणम्॥७७॥
फणीन्द्रविलसत्कण्ठंफणीन्द्रवलयान्वितम्।
मुनिवन्द्यं मुनिश्रेष्ठं एकबिल्वं शिवार्पणम्॥७८॥
नागेन्द्रविलसत्कर्णं भुजङ्गाभरणप्रियम्।
दक्षाध्वरविनाशञ्च एकबिल्वं शिवार्पणम्॥७९॥
मृगेन्द्रचर्मवसनं मुनिसाध्यैकजीवनम्।
सर्वदेवादिपूज्यञ्च एकबिल्वं शिवार्पणम्॥८०॥
निधनेशं धनाधीशमपमृत्युविनाशनम्।
लिंगमूर्तिमलिंगाख्यं एकबिल्वं शिवार्पणम्॥८१॥
भक्तकल्याणदं व्यस्तं वेदवेदान्तसंस्तुतम्।
कल्पकृत्कल्पनाशञ्च एकबिल्वं शिवार्पणम्॥८२॥
घोरपातकदावाग्निं जन्मकर्मविवर्जितम्।
कपालमालाभरणं एकबिल्वं शिवार्पणम्॥८३॥
मातङ्गचर्मवसनं विराड्रूपविधारकम्।
विष्णुक्रान्तमनन्तञ्च एकबिल्वं शिवार्पणम्॥८४॥
यज्ञकर्मफलाध्यक्षं यज्ञविघ्नविनाशकम्।
यज्ञेशं यज्ञभोक्तारं एकबिल्वं शिवार्पणम्॥८५॥
कालाधीशं त्रिकालज्ञं दुष्टनिग्रहकारकम्।
योगिमानसपूज्यञ्च एकबिल्वं शिवार्पणम्॥८६॥
महोन्नासं महाकायं महोदरं महाभुजम्।
महावृत्तं महावक्त्रं एकबिल्वं शिवार्पणम्॥८७॥

In Public domain. Digitization Muthulakshmi Research Academy

सुनेत्रं सुललाटञ्च शर्वं भीमपराक्रमम्।
महेश्वरं शिवकरं एकबिल्वं शिवार्पणम्॥८८॥
समस्तजगदाधारं समस्तगुणसागरम्।
सत्यं सत्यगुणोपेतं एकबिल्वं शिवार्पणम्॥८९॥
माघकृष्णचतुर्दश्यां पूजार्थञ्च जगद्गुरोः।
दुर्लभं सर्वदेवानां एकबिल्वं शिवार्पणम्॥९०॥
तत्रापि दुर्लभं मन्ये नभो मासेन्दुवासरे।
प्रदोषकाले पूजा च एकबिल्वं शिवार्पणम्॥९१॥
सालग्रामेषु विप्राणां तटाकशनकूपयोः।
कोटिकन्यामहादानं एकबिल्वं शिवार्पणम्॥९२॥
दर्शनं बिल्ववृक्षस्य स्पर्शनं पापनाशनम्।
अघोर पापसंहारं एकबिल्वं शिवार्पणम्॥९३॥
तुलसी नीलनिर्गुण्डी जम्बीरामलकं तथा।
अघोरपापसंहारं एकबिल्वं शिवार्पणम्॥९४॥
अखण्डबिल्वपत्रैश्च पूजयेन्नन्दिकेश्वरम्।
मुच्यते सर्वपापेभ्यः एकबिल्वं शिवार्पणम्॥९५॥
सालङ्कृतं सतां वृन्ते कन्याकोटिसहस्रकम्।
साम्राज्यपृथिवीदानञ्च एकबिल्वं शिवार्पणम्॥९६॥
दशकोटितुरङ्गाणामश्वमेधसहस्त्रकम्।
साम्राज्यपृथिवीदानं एकबिल्वं शिवार्पणम्॥९७॥
चतुर्वेदसहस्राणि भारतादिपुराणकम्।
तुलाभारं शतावृत्तिं एकबिल्वं शिवार्पणम्॥९८॥
सर्वरत्नमयं मेरुं काञ्चनं दिव्यवस्त्रकम्।
सवत्सधेनुकोटीनाम् एकबिल्वं शिवार्पणम्॥९९॥

In Public domain. Digitization Muthulakshmi Research Academy

अष्टोत्तरशतं बिल्वं योऽर्पयेल्लिङ्गमस्तके।
अथर्वोक्तं वदेद्यः स एकबिल्वं शिवार्पणम्॥१००॥
काशीक्षेत्रनिवासञ्च कालभैरवदर्शनम्।
अघोरपापसंहारं एकबिल्वं शिवार्पणम्॥१०१॥
अष्टोत्तरशतश्लोकैः स्तोत्राद्यैः पूजयेद्यदा।
त्रिसन्ध्यं मोक्षमाप्नोति एकबिल्वं शिवार्पणम्॥१०२॥
दन्तिकोटिसहस्राणां भूहिरण्यसहस्रकम्।
सर्वक्रतुमयं पुण्यम् एकबिल्वं शिवार्पणम्॥१०३॥
पुत्रपौत्रादिकं भोगं भुक्त्वा चात्र यथेप्सितम्।
अन्ते च शिवसायुज्यं एकबिल्वं शिवार्पणम्॥१०४॥
विप्रकोटिसहस्राणां भक्तगानाञ्च यत्फलम्।
तत्फलं प्राप्नुयात् सत्यं एकबिल्वं शिवार्पणम्॥१०५॥
त्वन्नामकीर्तनं तच्च तव पादाम्बु यः पिबेत्।
जीवन्मुक्तो भवेन्नित्यं एकबिल्वं शिवार्पणम्॥१०६॥
अनेकदानफलकमनन्तसुकृतादिकम्।
तीर्थयात्राखिलं पुण्यम् एकबिल्वं शिवार्पणम्॥१०७॥
त्वं मां पालय सर्वत्र पदध्यानकृशं तव।
भवनं शाङ्करं नित्यं एकबिल्वं शिवार्पणम्॥१०८॥
एककाले पठेन्नित्यं सर्वशत्रुनिवारणम्।
द्विकाले च पठेन्नित्यं एकबिल्वं शिवार्पणम्॥१०९॥
त्रिकाले च पठेन्नित्यं मनोवाञ्छाफलप्रदम्।
अचिरात् कार्यसिद्धिञ्च लभते नात्र संशयः॥११०॥
एककालं द्विकालं वा त्रिकालं यः पठेन्नरः।
लक्ष्मीप्राप्तिः शिवावासः शिवेन सह मोदते॥१११॥

In Public domain. Digitization Muthulakshmi Research Academy

कोटिजन्मकृतं पापं अर्चनेन विनश्यति।
सप्तजन्मकृतं पापं श्रवणेन विनश्यति॥११२॥
जन्मान्तरकृतं पापं श्रवणेन विनश्यति।
दिवारात्रिकृतं पापं दर्शनेन विनश्यति॥११३॥
क्षणे क्षणे कृतं पापं स्मरणेन विनश्यति।
पुस्तकं धारयेद्देह आरोग्यं भयनाशकम्॥११४॥

इति श्री शिवरहस्ये गौरीनारायण संवादे बिल्वाष्टोत्तरशतस्तोत्रं सम्पूर्णम्।

॥ शिव-मानस-पूजा ॥

रत्नैः कल्पित-मासनं हिमजलैः स्नानं च दिव्यांबरं
नानारत्न-विभूषितं मृगमदामोदांकितं चन्दनम्।
जाती-चंपक-बिल्वपत्र रचितं पुष्पं च धूपं तथा
दीपं देव दयानिधे पशुपते हृत्कल्पितं गृह्यताम्॥१॥

सौवर्णे नवरत्नखण्डरचिते पात्रे घृतं पायसं
भक्ष्यं पंचविधं पयोदधियुतं रंभाफलं पानकम्।
शाकानामयुतं जलं रुचिकरं कर्पूरखण्डोज्ज्वलं
तांबूलं मनसा मया विरचितं भक्त्या प्रभो स्वीकुरु॥२॥

छत्रं चामरयोर्युगं व्यजनकं चादर्शकं निर्मलं
वीणा-भेरि मृदंग-कोहलकला-गीतं च नृत्यं तथा।
साष्टांगं प्रणतिः स्तुति-र्बहुविधा ह्येतत् समस्तं मया
संकल्पेन समर्पितं तव विभो पूजां गृहाणे प्रभो॥३॥

आत्मा त्वं गिरिजा मतिः सहचराः प्राणाः शरीरं गृहं
पूजा ते विषयोपभोगरचना निद्रा समाधिस्थितिः।
संचारः पदयोः प्रदक्षिणविधिः स्तोत्राणि सर्वा गिरो
यद्यत्कर्म करोमि तत्तदखिलं शंभो तवाराधनम्॥४॥

In Public domain. Digitization Muthulakshmi Research Academy

करचरणकृतं वाक्कायजं कर्मजं वा
श्रवणनयनजं वा मानसं वापराधम्।
विहित-मविहितं वा सर्वमेतत्क्षमस्व
जय जय करुणाब्धे श्री महादेव शंभो ॥५॥

॥इति श्रीमच्छंकराचार्य-विरचिता शिवमानसपूजा समाप्ता॥

॥ शिव पञ्चाक्षर स्तोत्रम् ॥

(श्री शंकराचार्य कृतम्)

नागेन्द्र हाराय त्रिलोचनाय भस्मांग रागाय महेश्वराय।
नित्याय शुद्धाय दिगंबराय तस्मै नकाराय नमशिशवाय॥

मन्दाकिनी सलिल चन्दन चर्चिताय नन्दीश्वर प्रमथनाथ महेश्वराय।
मन्दार पुष्प बहु पुष्प सु पूजिताय तस्मै मकाराय नमशिशवाय॥

शिवाय गौरी वदनाब्ज बृन्द सूर्याय दक्षाध्वर नाशकाय।
श्री नीलकण्ठाय वृषध्वजाय तस्मै शिकाराय नमशिशवाय॥

वसिष्ठ कुम्भोद्भव गौतमादि मुनीन्द्र देवार्चित शेखराय।
चन्द्रार्क वैश्वानर लोचनाय तस्मै वकाराय नमशिशवाय॥

यक्ष स्वरूपाय जटाधराय पिनाक हस्ताय सनातनाय।
दिव्याय देवाय दिगंबराय तस्मै यकाराय नमशिशवाय॥

पञ्चाक्षर मिदं पुण्यं यः पठेच्छिव सन्निधौ।
शिवलोक मवाप्नोति शिवेन सह मोदते॥

॥ लिंगाष्टकम् ॥

१. ब्रह्म मुरारि सुरार्चित लिंगं - निर्मल भासित शोभित लिंगम्।
जन्मज दुःख विनाशक लिंगं - तत्प्रणमामि सदाशिव लिंगम्॥

In Public domain. Digitization Muthulakshmi Research Academy

२. देव मुनि प्रवरार्चित लिंगं - काम दहं करुणाकर लिंगम्।
रावणदर्प विनाशन लिंगं - तत्प्रणमामि सदाशिव लिंगम्॥
३. सर्व सुगन्धि सुलेपित लिंगं - बुद्धि विवर्धन कारण लिंगम्।
सिद्ध सुरा सुर वन्दित लिंगं - तत्प्रणमामि सदाशिव लिंगम्॥
४. कनक महामणि भूषित लिंगं - फणि पति वेष्टित शोभित लिंगम्।
दक्षसु यज्ञ विनाशन लिंगं - तत्प्रणमामि सदाशिव लिंगम्॥
५. कुंकुम चन्दन लेपित लिंगं - पंकज हार सुशोभित लिंगम्।
सञ्चित पाप विनाशन लिंगं - तत्प्रणमामि सदाशिव लिंगम्॥
६. देव गणार्चित सेवित लिंगं - भावै र्भक्ति भि रेवच लिंगम्।
दिनकर कोटि प्रभाकर लिंगं - तत्प्रणमामि सदाशिव लिंगम्॥
७. अष्ट दलो परि वेष्टित लिंगं - सर्व समुद्भव कारण लिंगम्।
अष्ट दरिद्र विनाशित लिंगं - तत्प्रणमामि सदाशिव लिंगम्॥
८. सुर गुरु सुरवर पूजित लिंगं - सुरवर पुष्प सदार्चित लिंगम्।
परात्परं परमात्मक लिंगं - तत्प्रणमामि सदाशिव लिंगम्॥

॥ श्री बिल्वाष्टकम्॥

त्रिदलं त्रिगुणाकारं त्रिनेत्रञ्चत्र्यायुषम्।
त्रिजन्मपाप संहारं एकबिल्वं शिवार्पणम्॥१॥

त्रिशाखैः बिल्वपत्रैश्च ह्यच्छिद्रैः कोमलैः शुभैः।
शिवपूजां करिष्यामि एक बिल्वं शिवार्पणम्॥२॥

अखण्ड बिल्वपत्रेण पूजिते नन्दिकेश्वरे।
शुध्यन्ति सर्वपापेभ्यः एकबिल्वं शिवार्पणम्॥३॥

सालग्रामशिलामेकां विप्राणां जातु चार्पयेत्।
सोमयज्ञमहापुण्यम् एकबिल्वं शिवार्पणम्॥४॥

In Public domain. Digitization Muthulakshmi Research Academy

दन्तिकोटिसहस्त्राणि वाजपेयशतानि च।
कोटिकन्यामहादानम् एकबिल्वं शिवार्पणम्॥५॥

लक्ष्म्यास्तनुत उत्पन्नं महादेवस्य च प्रियम्।
बिल्ववृक्षं प्रयच्छामि एक बिल्वं शिवार्पणम्॥६॥

दर्शनं बिल्ववृक्षस्य स्पर्शनं पापनाशनम्।
अघोर पापसंहारं एकबिल्वं शिवार्पणम्॥७॥

काशीक्षेत्र निवासं च कालभैरव दर्शनम्।
प्रयाग माधवं दृष्ट्वा एकबिल्वं शिवार्पणम्॥८॥

★★★

॥ श्री मार्गबन्धु स्तोत्रम्॥

(Recited during Alankara time after Abhishek to Shiva)

(श्री अप्पय्य दीक्षित कृत)

शंभो महादेव देव, शिव शंभो महादेव
देवेश शंभो, शंभो महादेव देव॥

१. फालावनम्रत्किरीटं, फाल-
नेत्रार्चिषा दग्ध पञ्चेषु कीटम्।
शूला हताराति कूटं शुद्ध-
मर्धेन्दुचूड़ं भजे मार्गबन्धुम्॥ (शंभो.......)

२. अङ्गे विराजत् भुजङ्गं अभ्र-
गंगातरङ्गाऽभि-रामोत्तमाङ्गम्।
ओङ्कार वाटी कुरङ्गं सिद्ध
संसेविताऽङ्घ्रिं भजे मार्गबन्धुम्॥ (शंभो.......)

३. नित्यं चिदानन्द रूपं निह्नु-
ताऽशेष लोकेष वैरि प्रतापम्।

In Public domain. Digitization Muthulakshmi Research Academy

कार्तस्वरागेन्द्र चापं कृत्ति-
वासं भजे दिव्य सन्मार्गबन्धुम्॥ (शंभो.......)

४. कन्दर्प दर्पघ्न मीशं काल-
कण्ठं महेशं महाव्योम केशम्।
कुन्दाभदन्तं सुरेशं कोटि-
सूर्य प्रकाशं भजे मार्गबन्धुम्॥ (शंभो.......)

५. मन्दार भूतेरुदारं मन्द-
रागेन्द्रं सारं महागौर्य दूरम्।
सिन्धूर दूर प्रचारं सिन्धु
राजानि धीरं भजे मार्गबन्धुम्॥ (शंभो.......)

६. अप्पय्य यज्वेन्द्र गीतं स्तोत्र-
राजं पठेद्यस्तु भक्त्या प्रयाणे।
तस्यार्थ सिद्धिं विधत्ते मार्ग-
मध्येऽभयं चातुतोषो महेशः॥
शंभो महादेव देव, शिव शंभो महादेव
देवेश शंभो, शंभो महादेव देव॥

॥ श्री वैद्यनाथाष्टकम्॥

(For redressal of various ailments)

१. श्री राम सौमित्रि जटायु वेद,
षडाननादित्य कुजार्चिताय।
श्री नीलकण्ठाय दयामयाय
श्री वैद्यनाथाय नमश्शिवाय॥

२. गङ्ग प्रवाहेन्दु जटाधराय,
त्रिलोचनाय स्मरकालहन्त्रे।
समस्त देवैरपि पूजिताय,
श्री वैद्यनाथाय नमश्शिवाय॥

In Public domain. Digitization Muthulakshmi Research Academy

३. भक्त प्रियाय त्रिपुरान्तकाय,
पिनाकिने दुष्टहराय नित्यम्।
प्रत्यक्ष लीलाय मनुष्यलोके,
श्री वैद्यनाथाय नमश्शिवाय॥

४. प्रभूत वातादि समस्त रोग,
प्रणाशकत्रे मुनि वन्दिताय।
प्रभाकरे न्द्वग्नि विलोचनाय,
श्री वैद्यनाथाय नमश्शिवाय॥

५. वाक् श्रोत्र नेत्रांघ्रि विहीनजन्तोः,
वाक्श्रोत्र नेत्रांघ्रि मुख प्रदाय।
कुष्टादि सर्वोन्नत रोगहन्त्रे,
श्री वैद्यनाथाय नमश्शिवाय॥

६. वेदान्त वेद्याय जगन्मयाय,
योगीश्वर ध्येय पदाम्बुजाय।
त्रिमूर्ति रूपाय सहस्त्रनाम्ने,
श्री वैद्यनाथाय नमश्शिवाय॥

७. स्वतीर्थऽमृत् भस्म भृदङ्ग भाजां,
पिशाच दुःखार्ति भयापहाय।
आत्म स्वरूपाय शरीर भाजां,
श्री वैद्यनाथाय नमश्शिवाय॥

८. श्री नीलकण्ठाय वृषध्वजाय,
स्त्रग्गन्ध भस्मा यभि शोभिताय।
सुपुत्र दारादि सुभाग्यदाय,
श्री वैद्यनाथाय नमश्शिवाय॥

९. बालांबिकेश वैद्येश,भवरोग हरेति च।
जपेन्नाम त्रयन्नित्यं, महारोग निवारणम्॥

★★★

In Public domain. Digitization Muthulakshmi Research Academy

APPENDICES

॥ पुरुषसूक्तम् ॥

(तै. आ. प्र.-३)

ॐ सहस्रशीर्षा पुरुषः। सहस्राक्षः सहस्रपात्। स भूमिं विश्वतो वृत्वा। अत्यतिष्ठद्दशाङ्गुलम्॥ पुरुष एवेदꣳ सर्वम्। यद्भूतं यच्च भव्यम्। उतामृतत्वस्येशानः। यदन्नेनातिरोहति॥ एतावानस्य महिमा। अतो ज्यायाꣳश्च पूरुषः॥१॥ पादोऽस्य विश्वा भूतानि। त्रिपादस्यामृतं दिवि॥ त्रिपादूर्ध्व उदैत्पुरुषः। पादोऽस्येहाऽभवात्पुनः। ततो विष्वङ्व्यक्रामत्। साशनानशने अभि॥ तस्माद्विराडजायत। विराजो अधि पूरुषः। स जातो अत्यरिच्यत। पश्चाद्भूमिमथो पुरः॥२॥ यत्पुरुषेण हविषा। देवा यज्ञमतन्वत। वसन्तो अस्यासीदाज्यम्। ग्रीष्म इध्मश्शरद्धविः॥ सप्तास्यासन्परिधयः। त्रिः सप्त समिधः कृताः। देवा यद्यज्ञं तन्वानाः। अबध्नन्पुरुषं पशुम्॥ तं यज्ञं बर्हिषि प्रौक्षन्। पुरुष ञ्जातमग्रतः॥३॥ तेन देवा अयजन्त। साध्या ऋषयश्च ये॥ तस्माद्यज्ञात्सर्वहुतः। संभृतं पृषदाज्यम्। पशूꣳस्ताꣳश्चक्रे वायव्यान्। आरण्यान्ग्राम्याश्च ये॥ तस्माद्यज्ञात्सर्वहुतः। ऋचः सामानि जज्ञिरे। छन्दाꣳसि जज्ञिरे तस्मात्। यजुस्तस्माद-जायत॥४॥ तस्मादश्वा अजायन्त॥ ये के चोभयादतः। गावो ह जज्ञिरे तस्मात्। तस्माज्जाता अजावयः॥ यत्पुरुषं व्यदधुः। कतिधाव्यकल्पयन्। मुखं किमस्य कौ बाहू। कावूरू पादावुच्येते॥ ब्राह्मणोऽस्य मुखमासीत्। बाहू राजन्यः कृतः॥५॥

In Public domain. Digitization Muthulakshmi Research Academy

ऊरू तदस्य यद्वैश्यः। पद्भ्या शूद्रो अजायत॥ चन्द्रमा मनसो जातः। चक्षोः सूर्यो अजायत। मुखादिन्द्रश्चाग्निश्च। प्राणाद्वायुरजायत॥ नाभ्या आसीदन्तरिक्षम्। शीर्ष्णो द्यौः समवर्तत। पद्भ्यां भूमिर्दिशः श्रोत्रात्। तथा लोका अकल्पयन्॥६॥ वेदाहमेतं पुरुषं महान्तम्। आदित्यवर्णं तमसस्तुपारे। सर्वाणि रूपाणि विचित्य धीरः। नामानि कृत्वाऽभिवदन् यदास्ते॥ धाता पुरस्ताद्यमुदाजहार। शक्रः प्रविद्वान् प्रदिशश्चतस्रः। तमेवं विद्वानमृत इह भवति। नान्यः पन्था अयनाय विद्यते॥ यज्ञेन यज्ञमयजन्त देवाः। तानि धर्माणि प्रथमान्यासन्। ते ह नाकं महिमानः सचन्ते। यत्र पूर्वे साध्याः सन्ति देवाः॥७॥

अद्भ्यः संभूतः पृथिव्यै रसाच्च। विश्वकर्मणः समवर्तताधि। तस्य त्वष्टा विदधद्रूपमेति। तत्पुरुषस्य विश्वमाजानमग्रे। वेदाहमेतं पुरुषं महान्तम्। आदित्यवर्णं तमसः परस्तात्। तमेवं विद्वानमृत इह भवति। नान्यः पन्था विद्यतेऽयनाय। प्रजापतिश्चरति गर्भे अन्तः। अजायमानो बहुधा विजायते॥८॥

तस्य धीराः परिजानन्ति योनिम्। मरीचीनां पदमिच्छन्ति वेधसः। यो देवेभ्य आतपति। यो देवानां पुरोहितः। पूर्वो यो देवेभ्यो जातः। नमो रुचाय ब्राह्मये। रुचं ब्राह्मं जनयन्तः। देवा अग्रे तदब्रुवन्। यस्त्वैवं ब्राह्मणो विद्यात्। तस्य देवा असन्वशे॥९॥

ह्रीश्च ते लक्ष्मीश्च पत्न्यौ। अहोरात्रे पार्श्वे। नक्षत्राणि रूपम्। अश्विनौ व्यात्तम्। इष्टं मनिषाण। अमुं मनिषाण। सर्वं मनिषाण॥१०॥

In Public domain. Digitization Muthulakshmi Research Academy

॥ नारायणसूक्तम् ॥

(तैत्तिरीयारण्यकम् प्र. १०, अनु १३)

सहस्रशीर्षं देवं विश्वाक्षं विश्वशंभुवम्। विश्वं नारायणं देवमक्षरं परमं पदम्। विश्वतः परमान्नित्यं विश्वं नारायणꣳ हरिम्। विश्वमेवेदं पुरुषस्तद्विश्वमुपजीवति। पतिं विश्वस्यात्मेश्वरꣳ शाश्वतꣳ शिवमच्युतम्। नारायणं महाज्ञेयं विश्वात्मानं परायणम्। नारायणपरो ज्योतिरात्मा नारायण परः। नारायणपरं ब्रह्म तत्वं नारायणः परः। नारायणपरो ध्याता ध्यानं नारायणः परः। यच्च किञ्चिज्जगत्थ्सर्वं दृश्यते श्रूयतेऽपि वा॥ अन्तर्बहिश्च तत्सर्वं व्याप्य नारायणः स्थितः। अनन्तमव्ययं कविꣳ समुद्रेऽन्तं विश्वशंभुवम्। पद्मकोशप्रतीकाशꣳ हृदयं चाप्यधोमुखम्। अधो निष्ट्या वितस्त्यान्ते नाभ्यामुपरि तिष्ठति। ज्वालमालाकुलं भाती विश्वस्यायतनं महत्। सन्ततꣳशिलाभिस्तु लम्बत्याकोशसन्निभम्। तस्यान्ते सुषिरꣳ सूक्ष्मं तस्मिन्थ्सर्वं प्रतिष्ठितम्। तस्य मध्ये महानग्नि विश्वार्चि विश्वतोमुखः। सोऽग्रभुग्विभजन्तिष्ठ न्नाहारमजरः कविः। तिर्यगूर्ध्वमधश्शायी रश्मयस्तस्य सन्तता। सन्तापयति स्वं देहमापादतलमस्तगः। तस्य मध्ये वह्निशिखा अणीयोर्ध्वा व्यवस्थितः। नीलतोयद-मध्यस्था-द्विद्युल्लेखेव भास्वरा। नीवारशूकवत्तन्वी पीता भास्वत्यणूपमा। तस्याः शिखाया मध्ये परमात्मा व्यवस्थितः। स ब्रह्म स शिवः स हरिः सेन्द्रः सोऽक्षरः परमः स्वराट्॥

ऋतꣳसत्यं परं ब्रह्म पुरुषं कृष्णपिङ्गलम्। ऊर्ध्वरेतं

In Public domain. Digitization Muthulakshmi Research Academy

विरूपाक्षं विश्वरूपाय वै नमो नमः ॥

नारायणाय विद्महे वासुदेवाय धीमहि। तन्नो विष्णुः प्रचोदयात् ॥

ॐ विष्णोर्नुकं वीर्याणि प्रवोचं यः पार्थिवानि विममे रजाꣳसि यो अस्कभायदुत्तरꣳ सदस्थं विचक्रमाणस्त्रेधोरुगायो विष्णो रराटमसि विष्णोः पृष्ठमसि विष्णोः श्नप्त्रेस्थो विष्णो स्स्यूरसि विष्णोर्ध्रुवमसि वैष्णवमसि विष्णवे त्वा ॥ ॐ शान्तिः शान्तिः शान्तिः ॥

॥ विष्णुसूक्तम् ॥

ॐ विष्णोर्नुकं वीर्याणि प्रवोचं यः पार्थिवानि विममे रजाꣳसि यो अस्कभायदुत्तरꣳ सधस्थं विचक्रमाणस्त्रेधोरुगायः ॥

तदस्य प्रियमभिपाथो अश्याम्। नरो यत्र देवयवोमदन्ति। उरुक्रमस्य स हि बन्धुरित्था। विष्णोः पदे परमे मध्व उथ्सः ॥ प्रतद्विष्णु स्स्तवते वीर्याय। मृगो न भीमः कुचरो गिरिष्ठाः। यस्योरुषु त्रिषु विक्रमणेषु। अधिक्षियन्ति भुवनानि विश्वा ॥ परो मात्रया तनुवा वृधान। न ते महित्वमन्वश्नुवन्ति। उभेते विद्म रजसी पृथिव्या विष्णो देवत्वम्। परमस्य विथ्से ॥

विचक्रमे पृथिवी मेष एताम्। क्षेत्राय विष्णुर्मनुषे दशस्यन्। ध्रुवासो अस्य कीरयो जनासः। ऊरुक्षितिꣳसुजनि- माचकार ॥ त्रिर्देवः पृथिवीमेष एताम्। विचक्रमे शतर्चसं महित्वा। प्रविष्णुरस्तु तवसस्तवीयान्। त्वेषꣳह्यस्य स्थविरस्य नाम।

In Public domain. Digitization Muthulakshmi Research Academy

अतो देवा अवन्तुनो यतो विष्णु र्विचक्रमे। पृथिव्यास्सप्त-धामभिः। इदं विष्णुर्विचक्रमे त्रेधा निदधे पदम्। समूढमस्यपाꣳसुरे। त्रीणि पदा विचक्रमे विष्णुर्गोपा अदाभ्यः। ततो धर्माणि धारयन्न्। विष्णोः कर्माणि पश्यत यतो व्रतानि पस्पशे। इन्द्रस्य युज्यस्सखा॥

तद्विष्णोः परमं पदꣳसदा पश्यन्ति सूरयः। दिवीव चक्षुराततम्। तद्विप्रासो विपन्यवो जागृवाꣳसस्समिन्धते। विष्णोर्यत्परमं पदम्॥

पर्याप्त्या अनन्तरायाय सर्वस्तोमोऽति रात्र उत्तममहर्भवति सर्वस्याप्त्यै सर्वस्यजित्त्यै सर्वमेव तेनाऽऽप्नोति सर्वं जयति॥

ॐ शान्तिः शान्तिः शान्तिः॥

॥ दुर्गासूक्तम् ॥

(तैत्तिरीयारण्यकम्ः ४ प्रपाठकः १० अनुवाकः २)

ॐ॥ जातवेदसे सुनवाम सोम मरातीयतो निदहाति वेदः। स नः पर्षदति दुर्गाणि विश्वा नावेव सिन्धुं दुरितात्यग्निः॥ तामग्निवर्णां तपसा ज्वलन्तीं वैरोचनीं कर्मफलेषु जुष्टाम्। दुर्गां देवीꣳशरणमहं प्रपद्ये सुतरसितरसे नमः॥ अग्ने त्वं पारया नव्यो अस्मान् थ्स्वस्तिभिरति दुर्गाणि विश्वा। पूश्च पृथ्वी बहुला न उर्वी भवा तोकाय तनयाय शंयोः॥ विश्वानि नो दुर्गहा जातवेदः सिन्धुन्न नावा दुरिताऽतिपर्षि। अग्ने अत्रिवन्मनसा गृणानोऽस्माकं बोध्यविता तनूनाम्॥ पृतना जितꣳ सहमानमुग्रमग्निꣳ हुवेम परमाथ्सधस्थात्। स नः पर्षदतिदुर्गाणि विश्वा क्षामद्देवो अति

In Public domain. Digitization Muthulakshmi Research Academy

दुरिताऽत्यग्निः ॥ प्रत्नोषि कमीड्यो अध्वरेषु सनाच्च होता नव्यश्च सत्सि। स्वाञ्चाऽग्ने तनुवं पिप्रयस्वाऽस्मभ्यं च सौभगमायजस्व॥ गोभिर्जुष्टमयुजो निषिक्तं तवेन्द्र विष्णोरनुसंचरेम। नाकस्य पृष्ठमभिसंवसानो वैष्णवीं लोक इह मादयन्ताम्॥

कात्यायनाय विद्महे कन्यकुमारि धीमहि। तन्नो दुर्गिः प्रचोदयात्॥

ॐ शान्तिः शान्तिः शान्तिः॥

॥ श्रीसूक्तम् ॥

(ऋ. सं. अष्टकम् ४, अ. ४, परि, सू.-११)

ॐ॥ हिरण्यवर्णां हरिणीं सुवर्णरजतस्रजाम्। चन्द्रां हिरण्मयीं लक्ष्मीं जातवेदो म आवह॥ तां म आवह जातवेदो लक्ष्मीमनपगामिनीम्। यस्यां हिरण्यं विन्देयं गामश्वं पुरुषानहम्॥ अश्वपूर्वां रथमध्यां हस्तिनादप्रबोधिनीम्। श्रियं देवीमुपह्वये श्रीर्मा देवीर्जुषताम्॥ कां सोऽस्मितां हिरण्यप्राकारामार्द्रां ज्वलन्तीं तृप्तां तर्पयन्तीम्। पद्मे स्थितां पद्मवर्णां तामिहोपह्वये श्रियम्॥ चन्द्रां प्रभासां यशसा ज्वलन्तीं श्रियं लोके देवजुष्टामुदाराम्। तां पद्मिनीमीं शरणमहं प्रपद्येऽलक्ष्मीर्मे नश्यतां त्वां वृणे॥ आदित्यवर्णे तपसोऽधिजातो वनस्पतिस्तव वृक्षोऽथ बिल्वः। तस्य फलानि तपसा नुदन्तु मायान्तरायाश्च बाह्या अलक्ष्मीः॥ उपैतु मां देवसखः कीर्तिश्च मणिना सह। प्रादुर्भूतोऽस्मि राष्ट्रेऽस्मिन् कीर्तिमृद्धिं ददातु मे॥ क्षुत्पिपासामलां ज्येष्ठामलक्ष्मीं नाशयाम्यहम्। अभूतिमसमृद्धिं च सर्वां निर्णुद मे

In Public domain. Digitization Muthulakshmi Research Academy

गृहात्॥ गन्धद्वारां दुराधर्षां नित्यपुष्टां करीषिणीम्। ईश्वरीं सर्वभूतानां तामिहोपह्वये श्रियम्॥ मनसः काममाकूतिं वाचः सत्यमशीमहि। पशूनां रूपमन्नस्य मयि श्रीः श्रयतां यशः॥ कर्दमेन प्रजाभूता मयि संभव कर्दम। श्रियं वासय मे कुले मातरं पद्ममालिनीम्॥ आपः सृजन्तु स्निग्धानि चिक्लीत वस मे गृहे। निच देवीं मातरं श्रियं वासय मे कुले॥ आर्द्रां पुष्करिणीं पुष्टिं सुवर्णां हेममालिनीम्। सूर्यां हिरण्मयीं लक्ष्मीं जातवेदो म आवह॥ आर्द्रां यः करिणीं यष्टिं पिङ्गलां पद्ममालिनीम्। चन्द्रां हिरण्मयीं लक्ष्मीं जातवेदो म आवह॥ तां म आवह जातवेदो लक्ष्मीमनपगामिनीम्। यस्यां हिरण्यं प्रभूतं गावो दास्योऽश्वान् विन्देयं पुरुषानहम्॥

यः शुचिः प्रयतो भूत्वा जुहुयादाज्यमन्वहम्। सूक्तं पञ्चदशर्चं च श्रीकामः सततं जपेत्॥ पद्मानने पद्म ऊरू पद्माक्षी पद्मसंभवे। तन्मे भजसि पद्माक्षी येन सौख्यं लभाम्यहम्॥ अश्वदायी गोदायी धनदायी महाधने। धनं मे जुषतां देवि सर्वकामांश्च देहि मे॥ पद्मानने पद्म विपद्म पत्रे पद्म प्रिये पद्म दलायताक्षि। विश्वप्रिये विश्वमनोऽनुकूले त्वत्पादपद्मं मयि सन्निधत् स्व॥ पुत्र पौत्रधनं धान्यं हस्त्यश्वादिगवे रथम्। प्रजानां भवसि माता आयुष्मन्तं करोतु माम्॥ धनमग्निर्धनं वायुर्धनं सूर्यो धनं वसुः। धनमिन्द्रो बृहस्पतिर्वरुणं धनमस्तु ते॥ वैनतेय सोमं पिब सोमं पिबतु वृत्रहा। सोमं धनस्य सोमिनो मह्यं ददातु सोमिनः॥ न क्रोधो न च मात्सर्यं न लोभो नाशुभा मतिः। भवन्ति कृतपुण्यानां भक्तानां श्रीसूक्तं जपेत्॥ वर्षन्तु ते विभावरि दिवो

In Public domain. Digitization Muthulakshmi Research Academy

अभ्रस्य विद्युतः। रोहन्तु सर्वं बीजान्यव ब्रह्म द्विषो जहि॥ (या सा पद्मासनस्था विपुल- कटितटी पद्मपत्रायताक्षी। गम्भीरा वर्तनाभिः स्तनभर नमिता शुभ्र वस्त्रोत्तरीया॥ लक्ष्मीर्दिव्यै गजेन्द्रैर्मणिगण खचितै स्नापिता हेमकुम्भैः।)

नित्यं सा पद्महस्ता मम वसतु गृहे सर्वमाङ्गल्ययुक्ता॥ लक्ष्मीं क्षीरसमुद्र राजतनयां श्रीरंगधामेश्वरीम्। दासीभूतसमस्त देव वनितां लोकैक दीपांकुराम्। श्रीमन्मन्दकटाक्षलब्ध विभव ब्रह्मेन्द्रगंगाधरां। त्वां त्रैलोक्य कुटुम्बिनीं सरसिजां वन्दे मुकुन्दप्रियाम्॥

सिद्धिलक्ष्मीर्मोक्षलक्ष्मी जयलक्ष्मीस्सरस्वती। श्रीलक्ष्मी-र्वरलक्ष्मीश्च प्रसन्ना मम सर्वदा। वरांकुशौ पाशमभीतिमुद्रां करैर्वहन्तीं कमलासनस्थाम्। बालार्क कोटि प्रतिभां त्रिणेत्रां भजेहमाद्यां जगदीश्वरीं त्वाम्॥

सर्वमङ्गलमाङ्गल्ये शिवे सर्वार्थ साधिके। शरण्ये त्र्यम्बके देवि नारायणि नमोऽस्तु ते॥

सरसिज-निलये सरोजहस्ते धवलतरांशुक गन्धमाल्य-शोभे। भगवति हरिवल्लभे मनोज्ञे त्रिभुवनभूतिकरि प्रसीद मह्यम्।

विष्णुपत्नीं क्षमां देवीं माधवीं माधवप्रियाम्। लक्ष्मीं प्रियसखीं देवीं नमाम्यच्युत-वल्लभाम्॥

महालक्ष्म्यै च विद्महे विष्णुपत्नी च धीमहि। तन्नो लक्ष्मीः प्रचोदयात्॥ श्री-वर्चस्व-मायुष्य-मारोग्य माविधाच्छोभमानं महीयते। धान्यं धनं पशुं बहुपुत्रलाभं शतसंवत्सरं दीर्घमायुः।

In Public domain. Digitization Muthulakshmi Research Academy

ऋणरोगादि-दारिद्र्य-पापक्षुदपमृत्यवः। भयशोकमनस्तापा नश्यन्तु मम सर्वदा॥

श्रियै जातः श्रिय आनिरियाय श्रियं वयो जनितृभ्यो दधातु। श्रियं वसाना अमृतत्वमायन् भजन्ति सद्यः सविता विदध्यून्॥ श्रिय एवैनं तच्छ्रियामादधाति। सन्ततमृचा वषट्कृत्यंसन्धत्तं संधीयते प्रजया पशुभिः। य एवं वेद॥ महादेव्यै च विद्महे विष्णुपत्न्यै च धीमहि। तन्नो लक्ष्मीः प्रचोदयात्॥

॥ भूसूक्तम् ॥

(तैत्तिरीय संहिता. काण्डम्-१ प्रपाठक. ५ अनुवाक. ३
तैत्तिरीय ब्राह्मणम् अष्टकम्. ३ प्रश्न. १ अनुवाक. २)

ॐ॥ भूमिर्भूम्नाद्यौर्वरिणाऽन्तरिक्षं महित्वा। उपस्थे ते देव्यदितेऽग्निमन्नाद-मन्नाद्यायादधे। आऽयङ्गौः पृश्निरक्रमी दसनन्मातरं पुनः। पितरं च प्रयन्थ्सुवः। त्रिꣳशद्धाम विराजति वाक्पतङ्गाय शिश्रिये। प्रत्यस्य वह द्युभिः। अस्य प्राणादपा-नत्यन्तश्चरति रोचना। व्यक्ख्यन् महिषः सुवः। यत्त्वा क्रुद्धः परोव-पमन्युना यदवर्त्या। सुकल्पमग्ने तत्तव पुनस्त्वोद्दीपयामसि। यत्ते मन्युपरोप्तस्य पृथिवीमनुदध्वसे। आदित्या विश्वे तद्देवा वसवश्च समाभरन्। मनो ज्योतिर्जुषता माज्यं विच्छिन्नं यज्ञꣳ समिमं दधातु। बृहस्पतिस्तनुता मिमन्नोविश्वे देवा इहमादयन्ताम्।

मेदिनी देवी वसुंधरा स्याद्वसुधा देवी वासवी। ब्रह्मवर्चसः पितृणां श्रोत्र ञ्चक्षुर्मनः। देवी हिरण्यगर्भिणी देवी प्रसोदरी।

In Public domain. Digitization Muthulakshmi Research Academy

रस॑ने स॒त्याय॑ने सीद॥ स॒मु॒द्रवती सावि॒त्रीह॒ नौ दे॒वी म॒ह्यकी॑॑। म॒हाधर॑णी म॒होऽर्य॑तिस्थ॥ शृ॒ङ्गे शृ॒ङ्गे य॒ज्ञे य॑ज्ञे विभ॒ीषणी॑॑। इन्द्र॑पत्नी व्या॒जनी सु॒रसित॑इह। वा॒युपरी जल॒शय॑नीस्व॒यंधा॒रा स॒त्यन्धो॒ परि॑मेदिनी। सो॒परि॑धत्तं गाय॥

वि॒ष्णु॒पत्नीं म॑हीं दे॒वीं मा॒धवीं॑॑ मा॑धव॒प्रियाम्। लक्ष्मीं॑ प्रि॒यस॑खीं दे॒वीं न॒माम्य॑च्यु॒त व॒ल्ल॑भाम्।

ध॒नु॒र्धरायै॑ वि॒द्महे सर्व॑सि॒द्ध्यै च॑ धीमहि। तन्नौ॑ धरा प्रचो॒दया॑॑त्॥ (म॒हीं दे॒वीं विष्णु॑पत्नी मजू॒र्या॑म्। प्र॒तीचीं मेनागं ह॒विषा॑ यजामः। त्रे॒धा विष्णु॑रुरुगा॒यो विच॑क्रमे। म॒हीं दिवं॑ पृथि॒वी-म॒न्तरि॑क्षम्। तच्छ्रो॒णैति॒ श्रव॑ इ॒च्छमा॑ना। पुण्य॒ँ॒ श्लोकं॒ यज॑मानाय कृण्व॒ती॥)

इक्षु शालि यव सस्य फलाढ्यां
पारिजात तरु शोभितमूले।
स्वर्ण रत्न मणिमण्टपमध्ये
चिन्तये त्सकल लोकधरित्रीम्॥
श्यामां विचित्रां नवरत्नभूषितां
चतुर्भजां तुङ्गपयोधरान्विताम्।
इन्दीवराक्षीं नव शालि मञ्जरीं
शुकं दधानां वसुधां भजामहे॥

सक्तु॑मिव॒ तित॑उना पु॒नन्तो॒ यत्र॒ धीरा॒ मन॑सा॒ वाच॒मक्रत। अत्रा॒ सखा॑य स्स॒ख्यानि॑ जानते भ॒द्रैषां॑ ल॒क्ष्मी नि॑हि॒ताधि॑वा॒चि।]

ॐ शान्ति॒ः शान्ति॒ः शान्ति॑ः॥

In Public domain. Digitization Muthulakshmi Research Academy

॥ नीळासूक्तम् ॥

(तैत्तिरीय संहिता. काण्डम्. ४ प्रपाठक. ४ अनुवाक. १२)

गृणाहि। घृतवती सवितराधिपत्यैः पयस्वतीरन्तिराशानो अस्तु। ध्रुवा दिशां विष्णुपत्न्यघोराऽस्येशाना सहसोया मनोता। बृहस्पति मातरिश्वोत वायुस्सन्धुवानावाता अभि नो गृणन्तु। विष्टम्भो दिवोधरुणः पृथिव्या अस्येशाना जगतो विष्णुपत्नी॥

ॐ शान्तिः शान्तिः शान्तिः॥

॥ मेधासूक्तम् ॥

(तैत्त्रीयारण्यकम्ः प्रश्नः १० अनुवाकः ४१-४४)

ॐ मेधादेवी जुषमाणा न आगाद्विश्वाची भद्रा सुमनस्यमाना। त्वया जुष्टा नुदमाना दुरुक्तान् बृहद्वदेम विदथे सुवीराः। त्वया जुष्ट ऋषिर्भवति देवि त्वया ब्रह्माऽऽगतश्रीरुत त्वया। त्वया जुष्टश्चित्रं विन्दते वसु सानो जुषस्व द्रविणो न मेधे॥

मेधां म इन्द्रो ददातु मेधां देवी सरस्वती। मेधां मे अश्विनावुभावाधत्तां पुष्करस्रजा। अप्सरासु च या मेधा गन्धर्वेषु च यन्मनः। दैवीं मेधा सरस्वती सा मां मेधा सुरभिर्जुषता ँ स्वाहा॥

आमां मेधा सुरभिर्विश्वरूपा हिरण्यवर्णा जगती जगम्या। ऊर्जस्वती पयसा पिन्वमाना सा मां मेधा सुप्रतीका जुषन्ताम्॥

मयि मेधां मयि प्रजां मय्यग्निस्तेजो दधातु मयि मेधां मयि प्रजां मयीन्द्र इन्द्रियं दधातु मयि मेधां मयि प्रजां मयि सूर्यो भ्राजो

In Public domain. Digitization Muthulakshmi Research Academy

दधातु॥ (हुंस हुंसाय विद्महे परम हुंसाय धीमहि। तन्नो हंसः प्रचोदयात्॥)

ॐ शान्तिः शान्तिः शान्तिः॥

॥ देवीसूक्तम् ॥

(ऋग्वेद-संहिताः मण्डलम्-१० (अष्टकम्-८), सूक्तम्-१२५)

ॐ॥ अहं रुद्रेभिर्वसुभिश्चराम्यहमादित्यैरुत विश्वदेवैः।
अहं मित्रावरुणोभा बिभर्म्यहमिन्द्राग्नी अहमश्विनोभा॥१॥
अहं सोममाहनसं बिभर्म्यहं त्वष्टारमुत पूषणं भगम्।
अहं दधामि द्रविणं हविष्मते सुप्राव्ये(३)यजमानाय सुन्वते॥२॥
अहं राष्ट्री संगमनी वसूनां चिकितुषी प्रथमा यज्ञियानाम्।
तां मा देवा व्यदधुः पुरुत्रा भूरिस्थात्रां भूर्यावेशयन्तीम्॥३॥
मया सोअन्नमत्ति यो विपश्यति यः प्राणिति यईं श्रृणोत्युक्तम्।
अमन्तवोमां त उपक्षियन्ति श्रुधिश्रुत श्रद्धिवं ते वदामि॥४॥
अहमेव स्वयमिदं वदामि जुष्टं देवेभिरुत मानुषेभिः।
यं कामये तं तमुग्रं कृणोमि तं ब्रह्माणं तमृषिं तं सुमेधाम्॥५॥
अहं रुद्राय धनुरातनोमि ब्रह्मद्विषे शरवेहन्त वा उ।
अहं जनाय समदं कृणोम्यहं द्यावापृथिवी आविवेश॥६॥
अहं सुवे पितरमस्य मूर्धन् मम योनिरप्स्व (१)न्तः समुद्रे।
ततो वितिष्ठे भुवनानु विश्वो तामूं द्यां वर्ष्मणोपस्पृशामि॥७॥
अहमेव वातइव प्रवाम्यारभमाणा भुवनानि विश्वा।
परो दिवा परएना पृथिव्यै तावती महिना संबभूव॥८॥

ॐ शान्तिः शान्तिः शान्तिः॥

In Public domain. Digitization Muthulakshmi Research Academy

॥ भाग्यसूक्तम् ॥

(तै-ब्रा- २-८-९)

प्रातरग्निं प्रातरिन्द्रꣳ हवामहे प्रातर्मित्रा वरुणा प्रातरश्विना। प्रातर्भगं पूषणं ब्रह्मणस्पतिं प्रातस्सोममुत रुद्रꣳ हुवेम॥१॥ प्रातर्जितं भगमुग्रꣳ हुवेम वयं पुत्र-मदितेर्यो विधर्ता। आद्ध्रश्चिद्यं मन्यमानस्तुरश्चित् राजा चिद्यं भगं भक्षीत्याह॥२॥ भग प्रणेत-र्भग सत्यराधो भगेमां धियमुदवददन्नः। भगप्रणो जनय गोभि रश्वैर्भगप्रनृभिर्नृवन्तस्स्याम॥३॥ उतेदानीं भगवन्तस्यामोत प्रपित्व उत मध्ये अह्नाम्। उतोदिता मघवन् सूर्यस्य वयं देवाना ꣳ सुमतौ स्याम॥४॥ भग एव भगवाꣳ अस्तु देवास्तेन वयं भगवन्तस्स्याम। तं त्वा भग सर्व इज्जोहवीमि सनो भग पुर एता भवेह॥५॥ समध्वरायोषसोनमन्त दधिक्रावेव शुचये पदाय। अर्वाचीनं वसुविदं भगन्नो रथमिवाश्वावाजिन आवहन्तु॥६॥ अश्वावती-र्गोमतीर्नउषासो वीरवतीःसदमुच्छन्तु भद्राः। घृतं दुहाना विश्वतः प्रपीना यूयं पात स्वस्तिभिस्सदा नः॥७॥ यो माऽग्ने भागिनꣳ सन्तमथाभागं चिकीर्षति। अभागमग्ने तं कुरु मामग्ने भागिनं कुरु स्वाहा॥८॥

ॐ शान्तिः शान्तिः शान्तिः॥

॥ ओषधि सूक्तम् ॥

(तै. सं. ४.२.६)

या जाता ओषधयो देवेभ्य स्त्रियुगं पुरा। मन्दामि बभ्रूणा मह

In Public domain. Digitization Muthulakshmi Research Academy

ँ शतन्धामानि सप्त च। शतं वो अंब धामानि सहस्र मुतवो रुहः। अथा शतक्रत्वो यूय मिमं मे अगदं कृत। पुष्पावतीः प्रसूवतीः फलिनी रफला उत। अश्वा इव सजित्वरी वीरुधः पारयिष्णवः। ओषधी रिति मातर स्तद्वो देवी रुप ब्रुवे। रपा ँ सि विघ्नतीरित रपश्चातय माना:। अश्वत्थे वो निषदनं पर्णेवो वसतिः कृता। गो भाज इत्किलासथ यथ्सनवथ पूरुषम्। यदहं वाजय न्निमा ओषधीर् हस्त आदधे। आत्मा यक्ष्मस्य नश्यति पुरा जीव गृभो यथा। यदोषधय स्संगच्छन्ते राजान स्समिता विव। विप्रस्स उच्यते भिषग्र क्षोहाऽमीव चातनः। निष्कृति र्नाम वो माताऽथा यूय ँ स्थ संकृतीः। सराः पतत्रिणीः स्थनयदाम यति निष्कृत। अन्यावो अन्या मव त्वन्याऽन्यस्या उपावत। ता स्सर्वा ओषधय स्संविदाना इदं मे प्रावता वचः। उच्छुष्मा ओषधीनां गावो गोष्ठादिवेरते। धन ँ सनिष्यन्तीना मात्मानं तव पूरुष। अति विश्वाः परिष्ठा स्स्तेन इव व्रजमक्रमुः। ओषधयः प्राचुच्यवु र्यत्किञ्च तनुवा ँ र पः। यास्त आतस्थुरात्मानं या आविविशुः परुः परुः। ता स्ते यक्ष्मं विबाधन्ता मुग्रो मध्यम शीरिव। साकं यक्ष्म प्रपत श्येनेन कि कि दीविना। साकं वातस्य ध्राज्या साकन्नश्यनिहाकया। अश्वावती ँ सोमवती मूर्जयन्ती मुदोजसम्। आविथ्सि सर्वा ओषधी रस्मा अरिष्ट तातये। याः फलिनीर्या अफला अपुष्पा याश्च पुष्पिणीः। बृहस्पति प्रसूता स्तानो मुञ्चन्त्व ँ हसः। या ओषधयः सोमराज्ञीः प्रविष्टाः पृथिवी मनु। तासान्त्वमस्युत्तमा प्रणो जीवातवे सुव। अवपतन्ती रवदन्दिव ओषधयः परि। यञ्जीव मश्नवा महै न सरिष्याति

In Public domain. Digitization Muthulakshmi Research Academy

पूरुषः। याश्चेदमुप शृण्वन्ति याश्च दूरं परागताः। इह संगत्य तास्सर्वा अस्मै सन्दत्त भेषजम्। मावोरिषत्खनिता यस्मै चाहंखनामिवः। द्विपच्चतुष्पदस्माक ँ सर्व मस्त्वनातुरम्। ओषधयः संवदन्ते सोमेन सह राज्ञा। यस्मै करोति ब्राह्मणस्त ँ राजन्पारया मसि॥

ॐ शान्तिः शान्तिः शान्तिः॥

॥ श्री गणेश सूक्तम् ॥

(ऋग्वेदीयम्) (ऋ. ८.८१.१-९)

आ तू न इन्द्र क्षुमन्तं चित्रं ग्राभं सं गृभाय। महाहस्ती दक्षिणेन॥ विद्मा हि त्वा तुविकूर्मिं तुविदेष्णं तुवीमघम्। तुविमात्रमवोभिः॥ न हि त्वा शूर देवा न मर्तासो दित्सन्तम्। भीमं न गां वारयन्ते॥ एतोन्विन्द्रं स्तवामेशानं वस्वः स्वराजम्। न राधसा मर्धिषन्नः॥ प्रस्तोषदुप गासिषच्छ्रवत्साम गीयमानम्। अभि-राधसा जुगुरत्॥ आ नो भर दक्षिणेनाभि सव्येन प्रमृश। इन्द्र मानो वसोर्निर्भाक्॥ उपक्रमस्वा भर धृषता धृष्णो जनानाम्। अदाशूष्टरस्य वेदः॥ इन्द्र य उ नु ते अस्ति वाजो विप्रेभिः सनित्वः। अस्माभिः सुतं सनुहि॥ सद्योजुवस्ते वाजा अस्मभ्यं विश्वश्चन्द्राः। वशैश्च मक्षू जरन्ते॥ निषु सीद गणपते गणेषु त्वामाहुर्विप्रतमं कवीनाम्। न ऋते त्वत्क्रियते किं चनारे महामर्कं मघवञ्चित्रमर्च॥ अभिख्यानो मघवन्नाधमानान्त्सखे बोधिवसुपते सखीनाम्। रणं कृधि रणकृत्सत्यशुष्माऽभक्ते चिदा भजा राये अस्मान्॥ गणानां त्वा गणपतिं हवामहे कविं कवीनामुपमश्रवस्तमम्। ज्येष्ठराजं ब्रह्मणां

In Public domain. Digitization Muthulakshmi Research Academy

ब्रह्मणस्पत आ नः शृण्वन्नूतिभिः सीद सादनम्। ओं शान्तिः शान्तिः शान्तिः।

॥ मन्यु सूक्तम् ॥

(ऋ. सं. १०-८३-७ एवं १०-८४-७)

१. यस्तै मन्योऽविधद्वज्र सायक सह ओजः पुष्यति विश्व मानुषक्।
साह्याम दास मार्यं त्वया युजा सहस्कृतेन सहसा सहस्वता॥

२. मन्युरिन्द्रो मन्यु रेवास देवो मन्युर्होता वरुणो जातवेदाः।
मन्युं विश ईळते मानुषीर्याः पाहिनो मन्यो तपसा सजोषाः॥

३. अभीहि मन्यो तव सस्तवीयान् तपसा युजा वि जहि शत्रून्।
अमित्रहा वृत्रहा दस्युहा च विश्वा वसून्या भरा त्वं नः॥

४. त्वं हि मन्यो अभि भूत्योजाः स्वयंभूर्भामो अभिमातिषाहः।
विश्व चर्षणिः सहुरिः सहावा नस्मा स्वोजः पृतनासु धेहि॥

५. अभागः सन्नप परेतो अस्मि तवक्रत्वा त विषस्य प्रचेतः।
तं त्वा मन्यो अक्रतुर्जिहीळा हं स्वा तनू बल देयाय मेहि॥

६. अयं ते अस्म्युप मेह्यर्वाङ् प्रतीचीनः सहुरे विश्वधायः।
मन्यो वज्रि न्नभि मामा ववृत्स्व हनाव दस्यू रुत बोध्यापेः॥

७. अभि प्रेहि दक्षिणतो भवा मेऽधा वृत्राणि जंघनाव भूरि।
जुहोमि ते धरुणं मध्वो अग्र मुभा उपांशु प्रथमा पिबाव॥

८. त्वया मन्यो सरथ मारु जन्तो हर्ष माणासो धृषिता मरुत्वः।
तिग्मेषव आयुधा संशिशाना अभि प्र यन्तु नरो अग्नि रूपाः॥

In Public domain. Digitization Muthulakshmi Research Academy

९. अग्निरिव मन्यो त्विषितः सहस्व सेनानीर्नः सहुरेहूत एधि।
हत्वाय शत्रून् विभजस्व वेद ओजो मिमानो वि मृधो नुदस्व॥

१०. सहस्व मन्यो अभिमातिमस्मे रुजन् मृणन् प्रमृणन् प्रेहि शत्रून्।
उग्रं ते पाजो नन्वा रुरुध्रे वशी वशं नयस एकज त्वम्॥

११. एको बहूनामसि मन्यवीळितो विशं विशं युधये संशिशाधि।
अकृत्तरुक् त्वया युजा वयं द्युमन्तं घोषं विजयाय कृण्महे॥

१२. विजेषकृदिन्द्र इवानवब्रवो(३)ऽस्माकं मन्यो अधिपा भवेह।
प्रियं ते नाम सहुरे गृणीमसि विद्मा तमुत्सं यत आबभूथ॥

१३. आभूत्या सहजा वज्र सायक सहो बिभर्ष्यभिभूत उत्तरम्।
क्रत्वा नो मन्यो सह मेद्येधि महाधनस्य पुरुहूत संसृजि॥

१४. संसृष्टं धनमुभयं समाकृतमस्मभ्यं दत्तां वरुणश्च मन्युः।
भियं दधाना हृदयेषु शत्रवः पराजितासो अप निलयन्ताम्॥

॥ ब्रह्मसूक्तम् ॥

(तै. ब्रा. २.८.८)

ब्रह्मजज्ञानं प्रथमं पुरस्तात्। विसीमतस्सुरुचो वेन आवः। सबुध्निया उपमा अस्य विष्ठाः। सतश्चयोनिमसतश्च विवः॥१॥

पिताविराजामृषभोरयीणाम्। अन्तरिक्षंविश्वरूप आविवेश। तमर्कैरभ्यर्चन्ति वत्सम्। ब्रह्मसन्तं ब्रह्मणा वर्द्धयन्तः॥२॥

ब्रह्मदेवानजनयत्। ब्रह्म विश्वमिदञ्जगत्। ब्रह्मणः खत्रन्निर्मितम्। ब्रह्म ब्राह्मण आत्मना॥३॥

In Public domain. Digitization Muthulakshmi Research Academy

अन्तरस्मिन्निमे लोकाः। अन्तर्विश्वमिदञ्जगत्। ब्रह्मैव भूतानाञ्ज्येष्ठम्। तेन कोऽर्हति स्पर्द्धितुम्॥४॥

ब्रह्मन्देवास्त्रयस्त्रिꣳशत्। ब्रह्मन्निन्द्रप्रजापती। ब्रह्मन् ह विश्वा भूतानि। नावीवान्तस्समाहिता॥५॥

चतस्र आशाः प्रचरन्त्वग्नयः। इमन्नो यज्ञन्नयतु प्रजानन्न्। घृतं पिन्वन्नजरꣳसुवीरम्। ब्रह्म समिद्भवत्याहुतीनाम्॥६॥

ॐ शान्तिः शान्तिः शान्तिः॥

॥ रुद्रसूक्तम् ॥

(तै. सं. ४-५-१०.१)

परिणोरुद्रस्य हेतिर्वृणक्तु परित्वेषस्य दुर्मतिरघायोः। अवस्थिरा मघवद्भ्यस्तनुष्वमीढ्वस्तोकाय तनयाय मृडय॥ स्तुहिश्रुतङ्गर्तसदं य्यु वानं मृगन्नभीममुपहत्लुमुग्रम्। मृडाजरित्रे रुद्रस्तवानो अन्यन्ते अस्मन्निवपन्तु सेनाः॥ मीढुष्टम शिवतम शिवोनस्सुमना भव। परमे वृक्ष आयुधन्निधाय कृत्तिंवसान आचरपिनाकं बिभ्रदागहि॥ अर्हन्बिभर्षि सायकानिधन्व। अर्हन्निष्कँयजतं विश्वरूपम्। अर्हन्निदन्दयसे विश्वमब्भुवम्। नवा ओजीयो रुद्रत्वदस्ति॥ त्वमग्ने रुद्रो असुरो महोदिवस्त्वꣳ शर्द्धो मारुतं पृक्ष ईशिषे। त्वं वातै ररुणैर्यासि शङ्गयस्त्वं पूषा विधतः पासि नुत्मना। आवोराजानमध्वरस्य रुद्रꣳहोतारꣳसत्ययजꣳ रोदस्योः। अग्निं पुरातनयित्लो रचित्ताद्धिरण्यरूप मवसे कृणुध्वम्॥

ॐ शान्तिः शान्तिः शान्तिः॥

In Public domain. Digitization Muthulakshmi Research Academy

॥ ओदन सूक्तम् ॥

(अन्न सूक्तम्)

(TO BE RECITED DURING ANNABHISHEKAM)

I. सिꣳहे व्याघ्र उतया पृदाकौ। त्विषि रग्नौ ब्राह्मणे सूर्येयो। इन्द्रं या देवी सुभगा जजान। सान आगन्वर्चसा संविदाना। याराजन्ये दुन्दु भावायतायाम्। अश्वस्य क्रन्द्ये पुरुषस्य मायौ। इन्द्रं या देवी सुभगा जजान। सान आग न्वर्चसा संविदाना। या हस्तिनि द्वीपिनि या हिरण्ये। त्विषि रश्वे षु पुरुषेषु गोषु॥१॥ इन्द्रं या देवी सुभगा जजान। सान आगन्वर्चसा संविदाना। रथै अक्षेषु वृषभस्य वाजे। वाते पर्जन्ये वरुणस्य शुष्मे। इन्द्रं या देवी सुभगा जजान। सान आग न्वर्चसा संविदाना। राडसि विराडसि। सम्राडसि स्वराडसि। इन्द्रायत्वा तेजस्वते तेजस्वन्त ꣳ श्रीणामि। इन्द्रायत्वौजस्वत ओजस्वन्तꣳ श्रीणामि॥२॥ इन्द्रायत्वा पयस्वते पयस्वन्त ꣳ श्रीणामि। इन्द्रा यत्वा ऽऽयुष्मत आयुष्मन्त ꣳ श्रीणामि। तेजो ऽसि। तत्ते प्रयच्छामि। तेजस्व दस्तु मे मुखम्। तेजस्वच्छिरो अस्तु मे। तेजस्वान् विश्वतः प्रत्यङ्। तेजसा संपि पृग्धिमा। ओजोसि। तत्ते प्रयच्छामि॥३॥ ओजस्व दस्तु मे मुखम्। ओजस्वच्छिरो अस्तु मे। ओजस्वान् विश्वतः प्रत्यङ्। ओजसा संपि पृग्धिमा। पयोऽसि। तत्ते प्रयच्छामि। पयस्व दस्तु मे मुखम्। पयस्वच्छिरो अस्तु मे। पयस्वान् विश्वतः प्रत्यङ्। पयसा संपिपृग्धिमा॥४॥ आयुरसि। तत्ते प्रयच्छामि। आयुष्मदस्तु मे मुखम्। आयुष्मच्छिरो अस्तुमे। आयुष्मान्

In Public domain. Digitization Muthulakshmi Research Academy

विश्वतः प्रत्यङ्ङ्। आयुषा संपि पृग्धिमा। इम मग्न आयुषे वर्चसे कृधि। प्रिय ँ रेतो वरुण सोम राजन्। माते वास्मा अदिते शर्मयच्च। विश्वेदेवा जरदष्टि यथाऽसत्॥५॥ आयुरसि विश्वायुरसि। सर्वायुरसि सर्वमायुरसि। यतो वातो मनो जवाः। यतः खरन्ति सिन्धवः। तासान्त्वा सर्वासा ँ रुचा। अभिषिञ्चामि वर्चसा। समुद्र इवासि गह्मना। सोम इवास्यदाभ्यः। अग्निरि व विश्वतः प्रत्यङ्ङ्। सूर्य इव ज्योतिषा विभूः॥६॥ अपां यो द्रवणे रसः। तमहमस्मा आमुष्यायणाय। तेजसे ब्रह्म वर्चसाय गृह्णामि। अपां य ऊर्मौ रसः। तमह मस्मा आमुष्या यणाय। ओजसे वीर्याय गृह्णामि। अपां यो मद्ध्यतो रसः। तमह मस्मा आमुष्या यणाय। पुष्टयै प्रजननाय गृह्णामि। अपां यो यज्ञियो रसः। तमह मस्मा आमुष्या यणाय। आयुषे दीर्घायुत्वाय गृह्णामि॥७॥ (तै. ब्रा., २.२.७.१६-२२)

II. अभिप्रेहि वीरयस्व। उग्रश्चेत्ता सपत्नहा। आतिष्ठ मित्र वर्द्धनः। तुभ्यन्देवा अधिबुवन्। अङ्कौ न्यङ्का वभित आतिष्ठ वृत्रहन्नथम्। (अंकौन्यङ्का वभितो रथंयौ ध्वान्तं वाताग्र मनु सञ्चरन्तौ दूरेहेति रिन्द्रि यावान् पतत्री तेनोऽग्नयः पप्रयः पारयन्तु॥ (तै. ब्रा., २.७.१६.५५, सं. १.७.७.८)॥ आतिष्ठ वृत्रहन्नथं युक्ता ते ब्रह्मणा हरी। अर्वाचीन ँ सुते मनो ग्रावा कृणोतु वग्नुना॥ (तै. सं. १.४.३७.१)॥ आतिष्ठन्तं परिविश्वे अभूषन्। श्रियं वसान श्चरति स्वरोचाः। महत्तदस्या सुरस्य

In Public domain. Digitization Muthulakshmi Research Academy

नाम। आ विश्वरूपो अमृतानि तस्थौ। अनुत्वेन्द्रो मद त्वनु बृहस्पतिः ॥८॥ अनुसोमो अन्वग्नि रावीत्। अनुत्वा विश्वेदेवा अवन्तु। अनुसप्त राजानोय उताभिषिक्ताः। अनुत्वा मित्रावरुणा विहावतम्। अनु द्यावा पृथिवी विश्व शंभू। सूर्यो अहोभि रनुत्वाऽवतु। चन्द्रमा नक्षत्रै रनुत्वाऽवतु। द्यौ श्चत्वा पृथिवी च प्रचेतसा। शुक्रो बृहद्दक्षिणा त्वा पिपर्तु। अनुस्वधा चिकिताꣳ सोमो अग्निः। आऽयं पृणक्तु रजसि उपस्थम्॥९॥ (तै. ब्रा., २.७.८.२३-२४)

III. प्रजापतिः प्रजा असृजत। ता अस्मा श्सृष्टाः पराचीरायन्। स एतं प्रजापति रोदन मपश्यत्। सोऽन्नं भूतोऽतिष्ठत्। ता अन्यत्रा न्नाद्य मवित्वा। प्रजापतिं प्रजा उपावर्तन्त। अन्न मेवैनं भूतं पश्यन्तीः प्रजा उपावर्तन्ते। य एतेन यजते। य उचैनमेवं वेद। सर्वाण्यन्नानि भवन्ति॥१०॥ सर्वे पुरुषाः। सर्वाण्येवा न्नान्य वरुन्धे। सर्वा न्पुरुषान्। राडसि विराडसीत्याह। स्वाराज्य मेवैनङ्गमयति। यद्धिरण्यन्ददाति। तेजस्तेना वरुन्धे। यत्ति सृधन्वम्। वीर्यन्तेन। यदष्ट्राम्॥११॥ पुष्टिन्तेन। यत्कमण्डलुम्। आयुष्टेन। यद्धिरण्यमा बद्धनाति। ज्योति वै हिरयम्। ज्योति रेवास्मि न्दधाति। अथो तेजोवै हिरण्यम्। तेज एवात्मन्धत्ते। यदोदनं प्राश्ज्ञाति। एत देव सर्व मवरुद्धय॥१२॥ तदस्मि न्नेकधाऽधात्। रोहिण्या ङ्कार्यः। यद्ब्राह्मण एव रोहिणी। तस्मा देव। अथो वर्ष्मै वैन ꣳ समानानां ङ्करोति। उद्यता सूर्येण

In Public domain. Digitization Muthulakshmi Research Academy

कार्यः। उद्यन्तं वा एत ँ सर्वाः प्रजाः प्रतिन न्दन्ति। दि दृक्षेण्यो दर्शनीयो भवति। य एवं वेद। ब्रह्मवादिनो वदन्ति॥१३॥ अवेत्यो ऽवभृथा (३) ना (३) इति। यद्दर्भ पुञ्जीलैः पवयति। तध्स्वि देवा वै ति। तन्नावै ति। त्रिभिः पवयति। त्रय इमे लोकाः। एभिरेवैनं ल्लोकैः पवयति। अथो अपां वा एतत्तेजो वर्चः। यद्दर्भाः। य द्दर्भ पुञ्जीलैः पवयति। अपा मैवैन न्तेजसा वर्चसाऽभिषिञ्चति॥ (तै. ब्रा., २.७.९)

IV. अन्नाद्वै प्रजाः प्रजायन्ते। याःकाश्च पृथिवी ँश्रिताः। अथो अन्नेनैव जीवन्ति। अथै न दपियन्त्यन्ततः। अन्न ँहि भूतानाञ्ज्येष्ठम्। तस्मा थ्सर्वौषध मुच्यते। सर्वं वै तेऽन्न माप्नुवन्ति। येऽन्नं ब्रह्मोपासते। अन्न ँहि भूतानाञ्ज्येष्ठम्। तस्मा थ्सर्वौषध मुच्यते। अन्ना द्भूतानि जायन्ते। जातान्यन्ने न वर्द्धन्ते। अद्यतेऽत्तिच भूतानि। तस्मा दन्नं तदुच्यत इति। तस्माद्वा एतस्मा दन्नर समयात्। अन्योऽन्तर आत्मा प्राणमयः। तेनै ष पूर्णः। सवा एष पुरुष विध एव। तस्य पुरुष विधताम्। अन्वयं पुरुष विधः। तस्य प्राण एव शिरः। व्यानो दक्षिणः पक्षः। अपान उत्तरः पक्षः। आकाश आत्मा। पृथिवी पुच्छं प्रतिष्ठा। तदप्येष श्लो को भवति॥ (तै. आ. ८.२)

V. प्राणन्देवा अनु प्राणन्ति। मनुष्याः पशवश्च ये। प्राणोहि भूताना मायुः। तस्मा थ्सर्वायुष मुच्यते। सर्वं मेवत आयुर्यन्ति। ये प्राणं ब्रह्मो पासते। प्राणोहि भूताना मायुः। तस्मा थ्सर्वायुष मुच्यत इति। तस्यैष एव शारी र आत्मा। यः पूर्वस्य। तस्माद्वा एतस्मात्

In Public domain. Digitization Muthulakshmi Research Academy

प्राण मयात्। अन्योऽन्तर आत्मा मनोमयः। तेनैष पूर्णः। सवा एष पुरुष विध एव। तस्य पुरुष विधताम्। अन्वयं पुरुष विधः। तस्य यजुरेव शिरः। ऋग् दक्षिणः पक्षः। सामोत्तरः पक्षः। आदेश आत्मा। अथर्वाङ्गिरसः पुच्छं प्रतिष्ठा। तदप्येष श्लोको भवति॥ (तै. आ. ८.३)

VI. यतो वाचो निवर्तन्ते। अप्राप्य मनसा सह। आनन्दं ब्रह्मणो विद्वान्। न बिभेति कदाचनेनि। तस्यैष एव शारीर आत्मा। यः पूर्वस्य। तस्माद्वा एतस्मा न्मनोमयात्। अन्योऽन्तर आत्मा विज्ञान मयः। तेनैष पूर्णः। सवा एष पुरुष विध एव। तस्य पुरुष विधताम्। अन्वयं पुरुष विधः। तस्य श्रद्धैव शिरः। ऋतन्दक्षिणः पक्षः। सत्य मुत्तरः पक्षः। योग आत्मा। महः पुच्छं प्रतिष्ठा। तदप्येष श्लोको भवति॥ (तै. आ. ८.४)

VII. अन्नं न निन्द्यात्। तद्व्रतम्। प्राणोवा अन्नम्। शरीर मन्नादम्। प्राणे शरीरं प्रतिष्ठितम्। शरीरे प्राणः प्रतिष्ठितः। तदेत दन्न मन्ने प्रतिष्ठितम्। सय एत दन्न मन्ने प्रतिष्ठितं वेद प्रतितिष्ठति। अन्नवान न्नादो भवति। महान्भवति प्रजया पशुभि र्ब्रह्मवर्चसेन। महान्कीर्त्या॥ (तै. आ. ९.७)

VIII. अन्नं न परिचक्षीत। तद् व्रतम्। आपो वा अन्नम्। ज्योतिष्यापः ज्योतिरन्नादम्। अप्सु ज्योतिः प्रतिष्ठितम्। ज्योतिष्यापः प्रतिष्ठिताः। तदेत दन्न मन्ने प्रतिष्ठितम्। सय एत दन्न मन्ने प्रतिष्ठितं वेद प्रति तिष्ठति। अन्नवान न्नादो भवति। महान्भवति प्रजया पशुभिर्ब्रह्मवर्च सेन। महान् कीर्त्या॥ (तै. आ. ९.८)

In Public domain. Digitization Muthulakshmi Research Academy

IX. अन्नं बहु कुर्वीत। तद् व्रतम्। पृथिवी वा अन्नम्। आकाशो ऽन्नादः। पृथिव्या माकाशः प्रतिष्ठितः। आकाशे पृथिवी प्रतिष्ठिता। तदेतदन्न मन्ने प्रतिष्ठितम्। सय एत दन्न मन्ने प्रतिष्ठितं वेद प्रति तिष्ठति। अन्नवान न्नादो भवति। महान्भवति। प्रजया पशुभि र्ब्रह्मवर्चसेन। महान्कीर्त्या॥ (तै. आ. ९.९)

X. न कञ्चन वसतौ प्रत्या चक्षीत। तद् व्रतम्। तस्माद्यया कया च विधया बह्वन्नं प्राप्नुयात्। अराद्ध्यस्मा अन्नमित्या चक्षते। एतद्वै मुख़तो ऽन्न ꣳराद्धम्। मुख़तोऽस्मा अन्नꣳराद्ध्यते। एतद्वै मध्यतो ऽन्नꣳराद्धम्। मध्यतोऽस्मा अन्नꣳराद्ध्यते। एतद्वा अन्ततौ ऽन्न ꣳ राद्धम्। अन्ततोऽस्मा अन्नꣳराद्ध्यते॥ य एवं वेद। क्षेम इति वाचि। योग क्षेम इति प्राणापानयोः। कर्मेति हस्तयोः। गतिरिति पादयोः। विमुक्ति रिति पायौ। इति मानुषी स्समाज्ञाः। अथ दैवीः। तृप्तिरिति वृष्टौ। बलमिति विद्युति॥ यश इति पशुषु। ज्योतिरिति नक्षत्रेषु। प्रजातिरमृत मानन्द इत्युपस्थे। सर्व मित्याकाशे। तत् प्रतिष्ठेत्युपासीत। प्रतिष्ठावान् भवति। तन्मह इत्युपा सीत। महान्भवति। तन्मन इत्युपासीत। मानवान् भवति॥ तन्मन इत्युपासीत। नम्यन्ते ऽस्मै कामाः। तद् ब्रह्मेत्युपासीत। ब्रह्मवान्भवति। तद्ब्रह्मणः परिमर इत्युपासीत। पर्येणं म्रियन्ते द्विषन्त स्सपत्नाः। परिये ऽप्रिया भ्रातृव्याः। स यश्चायं पुरुषे। यश्चासावा दित्ये। स एकः॥ सय एवं वित्। अस्माल्लो कात् प्रेत्य। एत मन्नमय मात्मान मुपसङ् क्रम्य। एतं प्राणमयमात्मान

In Public domain. Digitization Muthulakshmi Research Academy

मुपसङ्क्रम्य। एतं मनोमय मात्मान मुपसङ्क्रम्य। एतं विज्ञान मयमात्मान मुपसङ्क्रम्य। एतमानन्दमय मात्मान मुपसङ्क्रम्य। इमांल्लोकान् कामान्नी काम रूप्यनु सञ्चरन्। एत थ्सामगायन्नास्ते। हा (३) वुहा (३) वुहा (३) वु॥ अहमन्न महमन्न महमन्नम्। अहमन्नादोऽ (२) हमन्नादोऽ (२) हमन्नादः। अह ँ श्लोक कृदह ँ श्लोक कृदह ँ श्लोककृत्। अहमस्मि प्रथमजा ऋता (३) स्य। पूर्वन्देवेभ्यो अमृतस्य ना (३) भा इ। योमा ददाति स इ देवमा (३) वाः। अहमन्न मन्न मदन्त मा (३) द्मि। अहं विश्वं भुवनमभ्य भवाम्। सुवर्न ज्योतीः। य एवं वेद। इत्युपनिषत्॥ (तै. आ. ९.१०)

XI. अहमस्मि प्रथमजा ऋतस्य। पूर्वन्देवेभ्यो अमृतस्यनाभिः। योमाददाति सई देवमावाः। अहमन्न मन्न मदन्त मद्मि। पूर्व मग्ने रपिदहत्यन्नम्। यत्तौहा साते अहमुत्तरेषु। व्यात्तमस्य पशव स्सुजम्भम्। पश्यन्ति धीराः प्रचरन्ति पाकाः। जहाम्यन्य न्नजहा म्यन्यम्। अहमन्नं वश मिच्चरामि॥ समान मर्थं पर्यैमि भुञ्जत्। को मा मन्न मनुष्यो दयेत। पराके अन्न न्निहितं ल्लोक एतत्। विश्वै देवैः पितृभि गुप्त मन्नम्। यदद्यते लुप्यते यत्परोप्यते। शततमीसा तनूर्मे बभूव। महान्तौ चरू सकृदुग्धेन पप्रौ। दिवञ्च पृश्नि पृथिवीञ्च साकम्। तथ्सं पिबन्तो नमिनन्ति वेधसः। नैन द्भूयो भवति नोकनीयः॥ अन्नं प्राणमन्न मपान माहुः। अन्नं मृत्युन्तमु जीवातु माहुः। अन्नं ब्रह्माणो जरसं वदन्ति। अन्नमाहुः प्रजननं प्रजानाम्। मोघमन्नं विन्दते अप्रचेताः। सत्यं ब्रवीमि वध इथ्सतस्य। नार्यमणं पुष्यति नो

In Public domain. Digitization Muthulakshmi Research Academy

सखायम्। केवलाघो भवति केवलादी। अहं मेघ स्स्तनय वर्षन्नस्मि। मामदन्त्यहमद् म्यन्यान्। अह ँ सदमृतो भवामि। मदादित्या अधि सर्वे तपन्ति॥

॥ नवग्रहसूक्तम् ॥

I. आदित्यः (अधिदेवता = अग्निम्। प्रत्यधिदेवता = रुद्रम्।)

१. ॐ आसत्येन रजसा वर्तमानो निवेशयन्नमृतं मर्त्यं च। हिरण्ययेन सविता रथेनादेवो याति भुवना विपश्यन्॥ अग्निं दूतं वृणीमहे होतारं विश्ववेदसम्। अस्य यज्ञस्य सुक्रतुम्॥ येषामीशे पशुपतिः पशूना ञ्चतुष्पदामुत च द्विपदाम्। निष्क्रीतोऽयं यज्ञियं भागमैतु रायस्पोषा यजमानस्य सन्तु॥

ओं भूर्भुवस्सुवः। सूर्यं रक्तवर्णं, रक्तगन्धं, रक्तपुष्पं, रक्तमाल्यांबरधरं, रक्त छत्र ध्वज रथ पथाकादि शोभितं, दिव्य रथ समारूढ़ं, मेरुं दिव्यं प्रदक्षणी कुर्वाणं, प्राङ् मुखं, पद्मासनस्थं, द्विभुजं, सप्ताश्वं, सप्तरज्जुं, कलिंग देशाधिपतिं, काश्यप गोत्रं, प्रभव संवत्सर माघ शुक्ल सप्तम्यां, विशाखा नक्षत्रे जातं, सिम्ह राश्याधि पतिं, भानुवार प्रयुक्तं, किरीटिनं, सुखा सीनं, पत्नी पुत्र परिवार समेतं, ग्रह मंडले प्रविष्टं, अस्मिन्नधिकरणे मध्ये, वर्तुलाकार मंडले, गोधूमधान्योपरि भगवन्तं श्री सूर्यं आवाहयामि। स्थापयामि। पूजयामि॥

ॐ अधिदेवता-प्रत्यधिदेवता सहिताय भगवते आदित्याय नमः॥

In Public domain. Digitization Muthulakshmi Research Academy

II. अंगारकः (अधिदेवता=पृथिवी। प्रत्यधिदेवता=क्षेत्रपालकम्।)

२. ॐ अग्निर्मूर्द्धा दिवः ककुत्पतिः पृथिव्या अयम्। अपा ँरेता ँसि जिन्वति॥ स्योना पृथिवि भवाऽनृक्षरा निवेशनी। यच्छानश्शर्म सप्रथाः॥ क्षेत्रस्य पतिना वय ँहिते नैव जयामसि। गामश्वं पोषयित्वा स नो मृडातीदृशे॥

ओं भूर्भुव स्सुवः। अंगारकं रक्तवर्णं, रक्तगन्धं, रक्तपुष्पं, रक्तमाल्यांबरधरं, रक्त छत्र ध्वज रथ पथाकादि शोभितं, दिव्य रथ समारूडं, मेरुं प्रदक्षणि कुर्वाणं, मेषवाहनं, दक्षिणाभिमुखं, चतुर्भुजं, गदाशूल शक्ति धरं, अवन्ति देशाधिपतिं, भारद्वाजस गोत्रं, अक्षय संवत्सर, वैशाख़ कृष्ण द्वितीयायां, पूर्व फल्गुनी नक्षत्रे जातं, मेष वृश्चिक राश्याधिपतिं, भौमवार प्रयुक्तं, किरीटिनं, सुख़ासीनं, पत्नी पुत्र परिवार समेतं, ग्रह मण्डले प्रविष्टं, अस्मिन् अधिकरणे, सूर्य ग्रहस्य दक्षिण दिग्भागे, त्रिकोणाकार मण्डले, आढक धान्योपरि भगवन्तं अंगारकं आवाहयामि, स्थापयामि, पूजयामि॥

ॐ अधिदेवता-प्रत्यधिदेवतासहिताय भगवते अङ्गारकाय नमः॥

III. शुक्रः (अधिदेवता = इन्द्राणीम्। प्रत्यधिदेवता = इन्द्रम्।)

३. ॐ प्रवश्शुक्राय भानवे भरध्व ँहव्यं मतिं चाग्नये सुपूतम्। यो दैव्यानि मानुषा जनू ँष्यन्तर्विश्वानि विद्मना जिगाति॥ इन्द्राणीमासु नारिषु सुपत्नीमहमश्रवम्। न ह्यस्या अपरंचन जरसा मरते पतिः॥ इन्द्रं वो विश्वतस्परि हवामहे जनेभ्यः। अस्माकमस्तु केवलः॥

In Public domain. Digitization Muthulakshmi Research Academy

ओं भूर्भुव स्सुवः। शुक्रं श्वेत वर्णं, श्वेत गन्धं, श्वेत पुष्पं, श्वेत माल्यांबरधरं, श्वेत छत्र ध्वज रथ पथाकादि शोभितं, दिव्य रथ समारूढं, मेरुं दिव्यं प्रदक्षिणी कुर्वाणं पूर्वाभिमुखं पद्मा सनस्थं, चतुर्भुजं, दण्डाक्षमाला जटा वल्कल धारिणं, कांबोज देशाधिपतिं, भार्गवस गोत्रं, मन्मथ संवत्सर, श्रावण शुक्ल द्वादश्यां पुष्यमी नक्षत्रे जातं, तुला-वृषभ राश्याधि पतिं भृगुवार प्रयुक्तं, किरीटिनं, सुखासीनं, पत्नी पुत्र परिवार समेतं, ग्रह मण्डले प्रविष्टं, अस्मिन्नधिकरणे सूर्य ग्रहस्य प्राग्भागे पंचकोणाकार मण्डले, राजमाष धान्योपरि, भगवन्तं शुक्रं आवाहयामि, स्थापयामि, पूजयामि॥

ॐ अधिदेवता-प्रत्यधिदेवता-सहिताय भगवते शुक्राय नमः॥

IV. सोमः (अधिदेवता = अपः। प्रत्यधिदेवता = गौरीम्।)

४. ॐ आप्यायस्व समैतु ते विश्वतस्सोम वृष्णियम्। भवा वाजस्य संगथे॥ अप्सुमे सोमो अब्रवीदन्तर्विश्वानि भेषजा। अग्निञ्च विश्वशंभुवमापश्च विश्वभेषजीः॥ गौरी मिमाय सलिलानि तक्षत्येकपदी द्विपदी सा चतुष्पदी। अष्टापदी नवपदी बभूवुषी सहस्राक्षरा परमेव्योमन्॥

ओं भूर्भुव स्सुवः। चन्द्रं श्वेत वर्णं, श्वेत गन्धं, श्वेत पुष्पं, श्वेम माल्यांबरधरं, श्वेत छत्र ध्वज रथ पथाकादि शोभितं, दिव्य रथ समारूढं, मेरुं, दिव्यं प्रदक्षणी कुर्वाणं, दश अश्वरथ वाहनं, प्रत्यङ् मुखं, द्वि भुजं, दण्डधरं, यमुन देशाधिपतिं, आत्रेयस गोत्रं, नन्दन संवत्सर, कार्त्तिक शुक्ल चतुर्दश्यां कृत्तिकानक्षत्रे जातं,

In Public domain. Digitization Muthulakshmi Research Academy

कर्कटक राश्याधि पतिं, इन्दुवार प्रयुक्तं, किरीटिनं, सुखासीनं, पत्नी पुत्र परिवार समेतं, ग्रह मण्डले प्रविष्टं, अस्मि न्नधिकरणे सूर्य ग्रहस्य आग्नेय दिग्भागे सम चतुरश्र मण्डले, तण्डुल धान्योपरि भगवन्तं चन्द्रं आवाहयामि। स्थापयामि। पूजयामि॥

ॐ अधिदेवता-प्रत्यधिदेवता-सहिताय भगवते सोमाय नमः॥

V. बुधः (अधिदेवता=विष्णुः। प्रत्यधिदेवता=नारायणम्।)

५. ॐ उद्बुध्यस्वाग्ने प्रतिजागृह्येनमिष्टापूर्ते सᳪंसृजेथा-मयञ्च। पुनः कृण्वᳪंस्त्वा पितरं युवानमन्वाताᳪंसीत्त्वयि तन्तुमेतम्॥ इदं विष्णुर्विचक्रमे त्रेधा निदधे पदम्। समूढमस्य पाᳪं सुरे॥ विष्णो रराटमसि विष्णोः पृष्ठमसि विष्णोश्श्नप्त्रेस्थो विष्णोस्स्यूरसि विष्णो ध्रुवमसि वैष्णवमसि विष्णवे त्वा॥

ओं भूर्भुव स्सुवः। बुधं पीतवर्णं, पीतगन्धं, पीतपुष्पं, पीतमाल्यांबरधरं, पीत छत्र ध्वजरथ पताकादि शोभितं, दिव्य रथ समारूढं, मेरुं दिव्यं प्रदक्षणी कुर्वाणं, सिम्हवाहनं, उदङ् मुखं, चतुर्भुजं, खड्ग चर्मांबरं धरं, मगध देशाधिपतिं, आत्रेयस गोत्रं, सौम्य संवत्सर, भाद्रपद शुक्ल एकादश्यां, उत्तर फल्गुनी नक्षत्रे जातं, कन्या-मिथुन राश्याधिपतिं, सौम्य वासर प्रयुक्तं, पत्नी पुत्र परिवार समेतं, ग्रह मण्डले प्रविष्टं, अस्मिन् अधिकरणे, सूर्य ग्रहस्य ईशान्य दिग्भागे बाणाकार मण्डले, मुद्ग धान्योपरि भगवन्तं बुधं आवाहयामि, स्थापयामि, पूजयामि॥

ॐ अधिदेवता-प्रत्यधिदेवता-सहिताय भगवते बुधाय नमः॥

In Public domain. Digitization Muthulakshmi Research Academy

VI. बृहस्पतिः (अधिदेवता = इन्द्रमरुत्वम्। प्रत्यधिदेवता = ब्रह्माणम्।)

६. ॐ बृहस्पते अतियदर्यो अर्हाद्द्युमद्विभाति क्रतुमज्जनेषु। यद्दीदयच्छवसर्तप्रजात तदस्मासु द्रविणन्धेहि चित्रम्॥ इन्द्रमरुत्व इह पाहि सोमं यथा शार्याते अपिबस्सुतस्य। तव प्रणीती तव शूरशर्मन्नाविवासन्ति कवयस्सुयज्ञाः॥ ब्रह्मजज्ञानं प्रथमं पुरस्ताद्विसीमतस्सुरुचो वेन आवः। सबुध्निया उपमा अस्य विष्ठास्सतश्च योनिमसतश्च विवः॥

ओं भूर्भुव स्सुवः। बृहस्पतिं कनक वर्णं, कनक गन्धं, कनक पुष्पं, कनक माल्यांबरधरं, कनक छत्र ध्वज रथ पताकादि शोभितं, दिव्य रथ समारूढं, मेरुं दिव्यं प्रदक्षणी कुर्वाणं, पूर्वाभिमुखं पद्मासनस्थं, चतुर्भुजं, दण्डाक्षमाला धारिणं, सिन्धु द्वीप देशाधिपतिं, आंगीरस गोत्रं, सौम्य संवत्सर, आश्वयुज शुक्ल द्वादश्यां, धनिष्टा नक्षत्रे जातं, धनुर्मीन राश्याधिपतिं, गुरु वासर प्रयुक्तं, किरीटिनं, सुखासीनं, पत्नी पुत्र परिवार समेतं, ग्रह मण्डले प्रविष्टं अस्मिन्नधिकरणे, सूर्य ग्रहस्य उत्तर दिग्भागे, दीर्घ चतुरश्राकार मण्डले, चणक धान्योपरि, भगवन्तं बृहस्पतिं आवाहयामि। स्थापयामि। पूजयामि॥

ॐ अधिदेवता प्रत्यधिदेवतासहिताय भगवते बृहस्पतये नमः॥

VII. शनैश्चरः (अधिदेवता = यमम्। प्रत्यधिदेवता = प्रजापतिः।)

७. ॐ शन्नो देवीरभिष्टय आपो भवन्तु पीतये। शंयोर-

In Public domain. Digitization Muthulakshmi Research Academy

भिस्त्रवन्तु नः॥ प्रजापते न त्वदेतान्यन्यो विश्वा जातानि परिता बभूव। यत्कामास्ते जुहुमस्तन्नो अस्तु वयँस्याम पतयो रयीणाम्॥ इमं यमप्रस्तरमाहि सीदाङ्गिरोभिः पितृभिस्संविदानः। आत्वा मन्त्राः कविशस्ता वहन्त्वेना राजन् हविषा मादयस्व॥

ओं भूर्भुव स्सुवः। शनिं नीलवर्णं, नीलगन्धं, नीलपुष्पं, नीलमाल्यांबरधरं, नील छत्र ध्वज रथ पताकादि शोभितं, दिव्य रथ समारूढं, मेरुं दिव्यं प्रदक्षणी कुर्वाणं, चाप चनस्थं, प्रत्यङ् मुखं, गृध्र रथं, चतुर्भुजं, शूलायुध धरं, सौराष्ट्र देशाधिपतिं, विकारि संवत्सर, मार्गशीर्ष कृष्ण नवम्यां, रोहिणी नक्षत्रे जातं, मकर कुम्भ राश्याधिपतिं, मन्द वार प्रयुक्तं, किरीटिनं सुखासीनं, पत्नी पुत्र परिवार समेतं, ग्रह मण्डले प्रविष्टं, अस्मिन्नधिकरणे सूर्य ग्रहस्य पश्चिम दिग्भागे धनुराकार मण्डले श्वेत तिल धान्योपरि भगवन्तं शनैश्चरं आवाहयामि। स्थापयामि। पूजयामि॥

ॐ अधिदेवता प्रत्यधिदेवता-सहिताय भगवते शनैश्चराय नमः॥

VIII. राहुः (अधिदेवता = गाम्। प्रत्यधिदेवता = सर्पः।)

८. ॐ कया नश्चित्र आभुवदूती सदावृधस्सखा। कया शचिष्ठया वृता॥ आयङ्गौः पृश्निरक्रमीदसनन्मातरं पुनः। पितरञ्च प्रयन्थ्सुवः॥ यत्ते देवी निरृतिराबबन्ध दाम ग्रीवास्वविचर्त्यम्॥ इदन्ते तद्विष्याम्यायुषो न मध्यादथाजीवः पितुमद्धि प्रमुक्तः॥

In Public domain. Digitization Muthulakshmi Research Academy

ओं भूर्भुव स्सुवः। राहुं धूम्रवर्णं, धूम्र गन्धं, धूम्र पुष्पं, धूम्र माल्यांबरधरं, धूम्र छत्र ध्वज रथ पताकादि शोभितं, दिव्य रथ समारूढ़ं, मेरुं दिव्यं अप्रदक्षणी कुर्वाणं, सिम्हासनस्थं, नैर्ऋतिमुखं, शूर्पासनं, चतुर्भुजं, करालवक्त्रं, खड्ग चर्म वरकरं, पैठीनस गोत्रं, भर्भर देशाधिपतिं, राक्षस संवत्सर, माघ कृष्ण! चतुर्दश्यां, आश्लेषा नक्षत्रे जातं, भृगुवासर प्रयुक्तं, तुला राश्याधिपतिं, किरीटिनं, सुखासीनं, पत्नी पुत्र परिवार समेतं, ग्रह मण्डले प्रविष्टं, अस्मिन्नधिकरणे सूर्य ग्रहस्य निर्ऋति दिग्भागे, शूर्पाकार मण्डले, माष धान्योपरि भगवन्तं राहुं आवाहयामि। स्थापयामि। पूजयामि॥

IX. केतुः (अधिदेवता = ब्रह्माणम्। प्रत्यधिदेवता = चित्रगुप्तम्।)

ॐ अधिदेवता-प्रत्यधिदेवता-सहिताय भगवते राहवे नमः॥

९. ॐ केतुङ्कृण्वन्नकेतवे पेशो मर्या अपेशसे॥ समुषद्भिरजायथाः॥ ब्रह्मा देवानां पदवीः कवीनामृषिर्विप्राणां महिषो मृगाणाम्। श्येनो गृध्राणाꣳस्वधितिर्वनानाꣳसोमः पवित्रमत्येति रेभन्न्॥ सचित्रचित्रं चितयन्तमस्मे चित्रक्षत्र चित्रतमं वयोधाम्। चन्द्रं रयिं पुरुवीरं बृहन्तं चन्द्रचन्द्राभिर्गृणते युवस्व॥

ओं भूर्भुव स्सुवः। केतुं चित्रवर्णं, चित्रगन्धं, चित्रपुष्पं, चित्रमाल्यांबरधरं, चित्र छत्र ध्वज रथ पताकादि शोभितं, दिव्य रथ समारूढ़ं, मेरुं दिव्यं अप्रदक्षणी कुर्वाणं, ध्वजासनस्थं, दक्षिणाभिमुखं, अन्तर्वेदि देशाधिपतिं, द्वि बाहुं, गदा धरं, पैठीनस

In Public domain. Digitization Muthulakshmi Research Academy

गोत्रं, पार्थिव संवत्सर, फाल्गुण शुक्ल पौर्णम्यां, अभिजिन्नक्षत्रे जातं, सौम्यवार प्रयुक्तं, मिथुन राश्याधिपतिं, सिम्हासना सीनं, ग्रह मण्डले प्रविष्टं, अस्मिन्नधिकरणे सूर्यग्रहस्य वायु दिग्भागे, ध्वजाकार मण्डले, कुलुथ्थ धान्योपरि भगवन्तं केतुं आवाहयामि। स्थापयामि। पूजयामि॥

ॐ अधिदेवता-प्रत्यधिदेवता सहितेभ्यः भगवद्भ्यः केतुभ्यो नमः॥

॥ ॐ आदित्यादि नवग्रह देवताभ्यो नमो नमः॥

ॐ शान्तिः शान्तिः शान्तिः॥

॥ नक्षत्रसूक्तम् ॥

(तै. ब्रा.: अष्टकम्-३ प्रश्नः १ तै. संहिताः कां-२ प्रपाठक-५ अनु-१)

❖ कृत्तिकाः—ॐ॥ अग्निर्नः पातु कृत्तिकाः। नक्षत्रं देवमिन्द्रियम्। इदमासां विचक्षणम्। हविरासं जुहोतन। यस्य भान्ति रश्मयो यस्य केतवः। यस्येमा विश्वा भुवनानि सर्वा। सकृत्तिकाभिरभिसंवसानः। अग्निर्नो देव स्सुविते दधातु॥१॥

(अग्नये स्वाहा कृत्तिकाभ्यः स्वाहा।
अम्बायै स्वाहा दुलायै स्वाहा।
नितत्न्यै स्वाहाऽभ्रयन्त्यै स्वाहा।
मेघयन्त्यै स्वाहा वर्षयन्त्यै स्वाहा।
चुपुणीकायै स्वाहा।)

❖ रोहिणीः—प्रजापते रोहिणीवैतु पत्नी। विश्वरूपा बृहती चित्रभानुः। सा नो यज्ञस्य सुविते दधातु। यथा जीवेम

In Public domain. Digitization Muthulakshmi Research Academy

शरदस्सवीराः। रोहिणी देव्युदगात्पुरस्तात्। विश्वा रूपाणि प्रतिमोदमाना। प्रजापतिꣳ हविषा वर्द्धयन्ती। प्रिया देवाना-मुपयातु यज्ञम्॥ २॥

(प्रजापतये स्वाहा रोहिण्यै स्वाहा।
रोचमानायै स्वाहा प्रजाभ्यः स्वाहा।)

❖ मृगशिराः—सोमो राजा मृगशीर्षेण आगन्न्। शिवं नक्षत्रं प्रियमस्य धाम। आप्यायमानो बहुधा जनेषु। रेतः प्रजां यजमाने दधातु। यत्ते नक्षत्रं मृगशीर्षमस्ति। प्रियꣳ राजन् प्रियतमं प्रियाणाम्। तस्मै ते सोम हविषा विधेम। शन्न एधि द्विपदे शञ्चतुष्पदे॥ ३॥

(सोमाय स्वाहा मृगशीर्षाय स्वाहा।
इन्वकाभ्यः स्वाहौषधीभ्यः स्वाहा।
राज्याय स्वाहाऽभिजित्यै स्वाहा।)

❖ आर्द्राः—आर्द्रया रुद्रः प्रथमान एति। श्रेष्ठो देवानां पतिरघ्नियानाम्। नक्षत्रमस्य हविषा विधेम। मानः प्रजाꣳ रीरिषन्मोत वीरान्। हेती रुद्रस्य परिणो वृणक्तु। आर्द्रा नक्षत्रं जुषताꣳ हविर्नः। प्रमुञ्चमानौ दुरितानि विश्वा। अपाघशꣳ-सन्नुदता- मरातिम्॥ ४॥

(रुद्राय स्वाहाऽऽर्द्रायै स्वाहा।
पिन्वमानायै स्वाहा पशुभ्यः स्वाहा॥)

❖ पुनर्वसूः—पुनर्नो देव्यदितिस्स्पृणोतु। पुनर्वसूनः पुनरेतां यज्ञम्। पुनर्नो देवा अभियन्तु सर्वे। पुनः पुनर्वो हविषा यजामः। एवा न देव्यदितिरनर्वा। विश्वस्य भर्त्री जगतः प्रतिष्ठा। पुनर्वसू

In Public domain. Digitization Muthulakshmi Research Academy

हविषा वर्द्धयन्ती। प्रियं देवानामप्यैतु पाथः॥ ५॥

(अदित्यै स्वाहा पुनर्वसुभ्याम्।
स्वाहा भूत्यै स्वाहा प्रजात्यै स्वाहा॥)

❖ पुष्यः—बृहस्पतिः प्रथमं जायमानः। तिष्यं नक्षत्रमभिसंबभूव। श्रेष्ठो देवानां पृतनासुजिष्णुः। दिशो नु सर्वा अभयन्नो अस्तु। तिष्यः पुरस्तादुत मध्यतो नः। बृहस्पतिर्नः परिपातु पश्चात्। बाधेतान्द्वेषो अभयं कृणुताम्। सुवीर्यस्य पतयस्स्याम॥ ६॥

(बृहस्पतये स्वाहा तिष्याय स्वाहा।
ब्रह्मवर्चसाय स्वाहा॥)

❖ आश्लेषाः—इदꣳ सर्पेभ्यो हविरस्तु जुष्टम्। आश्रेषायेषा मनुयन्ति चेतः। ये अन्तरिक्षं पृथिवीं क्षियन्ति। तेनस्सर्पासो हवमागमिष्ठाः। ये रोचने सूर्यस्यापि सर्पाः। ये दिवं देवी- मनुसञ्चरन्ति। येषा माश्रेषा अनुयन्ति कामम्। तेभ्यस्सर्पेभ्यो मधुमज्जुहोमि॥ ७॥

(सर्पेभ्यः स्वाहाऽऽश्रेषाभ्यः स्वाहा।
दन्दशूकेभ्यः स्वाहा।)

❖ मघाः—उपहूताः पितरो ये मघासु। मनोजवसस्सुकृतस्सुकृत्याः। ते नो नक्षत्रे हव मागमिष्ठाः। स्वधाभिर्यज्ञं प्रयतं जुषन्ताम्। ये अग्निदग्धा येऽनग्निदग्धाः। येऽमुल्लोकं पितरः क्षियन्ति। याꣳश्च विद्मयाꣳ उ च न प्रविद्म। मघासु यज्ञꣳ सुकृतं जुषन्ताम्॥ ८॥

(पितृभ्यः स्वाहा मघाभ्यः। स्वाहा ऽनघाभ्यः

In Public domain. Digitization Muthulakshmi Research Academy

स्वाहाऽगदाभ्यः। स्वाहाऽरुन्धतीभ्यः स्वाहा।)

❖ पूर्व फल्गुनीः—गवां पतिः फल्गुनीनामसि त्वम्। तदर्यमन् वरुणमित्र चारु। तं त्वा वयꣳ सनितारꣳ सनीनाम्। जीवा जीवन्तमुपसंविशेम। येनेमा विश्वा भुवनानि सञ्जिता। यस्य देवा अनु संयन्ति चेतः। अर्यमा राजाऽजरस्तु विष्मान्। फल्गुनीनामृषभो रोरवीति॥ ९॥

(अर्यम्णे स्वाहा फल्गुनीभ्याꣳ स्वाहा। पशुभ्यः स्वाहा।)

❖ उत्तर फल्गुनीः—श्रेष्ठो देवानां भगवो भगासि। तत्त्वा विदुः फल्गुनीस्तस्य वित्तात्। अस्मभ्यं क्षत्रमजरꣳ सुवीर्यम्। गोमदश्ववदुपसन्नुदेह। भगोह दाता भग इत्प्रदाता। भगो देवीः फल्गुनीराविवेश। भगस्येत्तं प्रसवं गमेम। यत्र देवैस्सधमादं मदेम॥१०॥

(भगायस्वाहा फल्गुनीभ्याꣳ स्वाहा। श्रैष्ठ्याय स्वाहा।)

❖ हस्ताः—आयातु देवस्सवितोप यातु। हिरण्ययेन सुवृता रथेन। वहन् हस्तꣳ सुभगं विद्मनापसम्। प्रयच्छन्तं पपुरिं पुण्यमच्छ। हस्तः प्रयच्छ त्वमृतं वसीयः। दक्षिणेन प्रतिगृभ्णीम एनत्। दाता रमद्य सविता विदेय। यो नो हस्ताय प्रसुवाति यज्ञम्॥११॥

(सवित्रेस्वाहा हस्ताय। स्वाहा ददते स्वाहा पृणते।
स्वाहा प्रयच्छते स्वाहा प्रतिगृभ्णते स्वाहा।)

❖ चित्रा—त्वष्टा नक्षत्रमभ्येति चित्राम्। सुभꣳ ससंयुवतिꣳ रोचमानाम्। निवेशयन्नमृतान्मर्त्याꣳश्च। रूपाणि पिꣳशन् भुवनानि विश्वा। तन्नस्त्वष्टा तदु चित्रा विचष्टाम्।

In Public domain. Digitization Muthulakshmi Research Academy

तन्नक्षत्रं भूरिदा अस्तु मह्यम्। तन्नः प्रजां वीरवतीᳪं सनोतु। गोभिर्नो अश्वैस्समनक्तु यज्ञम्॥१२॥

(त्वष्ट्रे स्वाहा चित्रायै स्वाहा।
चैत्राय स्वाहा प्रजायै स्वाहा।)

❖ स्वातीः—वायुर्नक्षत्रमभ्यैति निष्ट्याम्। तिग्मशृंगो वृषभो रोरुवाणः। समीरयन् भुवना मातरिश्वा। अप द्वेषाᳪंसि नुदतामरातीः। तन्नो वायुस्तदु निष्ट्या शृणोतु। तन्नक्षत्रं भूरिदा अस्तु मह्यम्। तन्नो देवासो अनु जानन्तु कामम्। यथा तरेम दुरितानि विश्वा॥१३॥

(वायवे स्वाहा निष्ट्यायै स्वाहा।
कामचाराय स्वाहाऽभिजित्यै स्वाहा।)

❖ विशाखाः—दूरमस्मच्छत्रवो यन्तु भीताः। तदिन्द्राग्नी कृणुतां तद्विशाखे। तन्नो देवा अनुमदन्तु यज्ञम्। पश्चात् पुरस्तादभयन्नो अस्तु। नक्षत्राणामधिपत्नी विशाखे। श्रेष्ठाविन्द्राग्नी भुवनस्य गोपौ। विषूचश्शत्रूनपबाधमानौ। अपक्षुधन्नुदतामरातिम्॥१४॥

(इन्द्राग्निभ्याᳪं स्वाहा विशाखाभ्याᳪं स्वाहा!
श्रैष्ठ्याय स्वाहाऽभिजित्यै स्वाहा।)

❖ पूर्णिमाः—पूर्णा पश्चादुत पूर्णा पुरस्तात्। उन्मध्यतः पौर्णमासी जिगाय। तस्यां देवा अधिसंवसन्तः। उत्तमे नाक इह मादयन्ताम्। पृथ्वी सुवर्चा युवतिः सजोषाः। पौर्णमास्युदगाच्छोभमाना। आप्याययन्ती दुरितानि विश्वा। उरुंदुहां यजमानाय

In Public domain. Digitization Muthulakshmi Research Academy

यज्ञम्॥१५॥

(पौर्णमास्यै स्वाहा कामाय स्वाहा गत्यै स्वाहा॥)

❖ अनुराधाः—ऋद्ध्यास्महव्यैर्नमसोपसद्य। मित्रं देवं मित्रधेयं नो अस्तु। अनूराधान् हविषा वर्धयन्तः। शतं जीवेम शरदः सवीराः। चित्रं नक्षत्रमुदगात्पुरस्तात्। अनूराधा स इति यद्वदन्ति। तन्मित्र एति पथिभिर्देवयानैः। हिरण्ययै- र्विततै-रन्तरिक्षे॥१६॥

(मित्राय स्वाहाऽनूराधेभ्यः स्वाहा।
मित्रधेयाय स्वाहाऽभिजित्यै स्वाहा।)

❖ ज्येष्ठाः—इन्द्रो ज्येष्ठामनु नक्षत्रमेति। यस्मिन् वृत्रं वृत्र तूर्ये ततार। तस्मिन्वय-ममृतं दुहानाः। क्षुधन्तरेम दुरितिं दुरिष्टिम्। पुरन्दराय वृषभाय धृष्णवे। अषाढाय सहमानाय मीढुषे। इन्द्राय ज्येष्ठा मधुमहुहाना। उरुं कृणोतु यजमानाय लोकम्॥१७॥

(इन्द्रायस्वाहा ज्येष्ठायै स्वाहा।
ज्यैष्ठ्याय स्वाहाऽभिजित्यै स्वाहा।)

❖ मूलम्—मूलं प्रजां वीरवतीं विदेय। परा च्येतु निर्ऋतिः पराचा। गोभिर्नक्षत्रं पशुभिस्समक्तम्। अहर्भूयाद्य जमानाय मह्यम्। अहर्नो अद्य सुविते दधातु। मूलं नक्षत्रमिति यद्वदन्ति। पराचीं वाचा निर्ऋतिं नुदामि। शिवं प्रजायै शिवमस्तु मह्यम्॥१८॥

(प्रजापतये स्वाहा मूलायस्वाहा। प्रजायै स्वाहा।)

In Public domain. Digitization Muthulakshmi Research Academy

❖ पूर्वाषाढाः—या दिव्या आपः पयसा संबभूवुः। या अन्तरिक्ष उत पार्थिवीर्याः। यासा-मषाढा अनुयन्ति कामम्। ता न आपः शꣳ स्योना भवन्तु। याश्च कूप्या याश्च नाद्यास्समुद्रियाः। याश्च वैशन्तीरुत प्रासचीर्याः। यासामषाढा मधु भक्षयन्ति। ता न आपः शꣳ स्योना भवन्तु॥१९॥

(अद्भ्यः स्वाहाऽषाढाभ्यः स्वाहा।
समुद्राय स्वाहा कामाय स्वाहा। अभिजित्यै स्वाहा।)

❖ उत्तराषाढाः—तन्नो विश्वे उप शृण्वन्तु देवाः। तदषाढा अभिसंयन्तु यज्ञम्। तन्नक्षत्रं प्रथतां पशुभ्यः। कृषिर्वृष्टि र्यजमानाय कल्पताम्। शुभ्राः कन्या युवतयस्सुपेशसः। कर्मकृत-स्सुकृतो वीर्यावतीः। विश्वान् देवान् हविषा वर्द्धयन्तीः। अषाढाः काममुपयान्तु यज्ञम्॥२०॥

(विश्वेभ्यो देवेभ्यः स्वाहाऽषाढाभ्यः स्वाहा।
अनपजय्याय स्वाहा जित्यै स्वाहा॥)

❖ अभिजित्:—यस्मिन् ब्रह्माभ्यजयत्सर्व मेतत्। अमुंच लोकमिदमूच सर्वम्। तन्नो नक्षत्र मभिजिद्विजित्य। श्रियं दधात्वहृणीयमानम्। उभौ लोकौ ब्रह्मणा संजितेमौ। तन्नो नक्षत्रमभिजिद्विचष्टाम्। तस्मिन्वयं पृतनास्संजयेम। तन्नो देवासो अनु जानन्तु कामम्॥२१॥

(ब्रह्मणे स्वाहाऽभिजिते स्वाहा।
ब्रह्मलोकाय स्वाहाऽभिजित्यै स्वाहा।)

❖ श्रवणम्—शृण्वन्ति श्रोणा-ममृतस्य गोपाम्। पुण्यामस्या

In Public domain. Digitization Muthulakshmi Research Academy

उपश्रृणोमि वाचम्। महीं देवीं विष्णुपत्नीमजूर्याम्। प्रतीचीमेनाᳲ हविषा यजामः। त्रेधा विष्णुरुरुगायो विचक्रमे। महीं दिवं पृथिवी-मन्तरिक्षम्। तच्छ्रोणैति श्रव इच्छमाना। पुण्यᳲ श्लोकं यजमानाय कृण्वती॥२२॥

(विष्णवे स्वाहा श्रोणायै स्वाहा।
श्लोकाय स्वाहा श्रुतायस्वाहा।)

❖ श्रविष्ठाः—अष्टौ देवा वसवस्सोम्यासः। चतस्रो देवी-रजराः श्रविष्ठाः। ते यज्ञं पान्तु रजसः परस्तात्। संवत्सरीण-ममृतᳲ स्वस्ति। यज्ञं नः पान्तु वसवः पुरस्तात्। दक्षिणतो-ऽभियन्तु श्रविष्ठाः। पुण्यन्नक्षत्रमभिसंविशाम। मा नो अराति-रघशᳲसागन्॥२३॥

(वसुभ्यः स्वाहा श्रविष्ठाभ्यः स्वाहा।
अग्राय स्वाहा परीत्यै स्वाहा।)

❖ शतभिषग्ः—क्षत्रस्य राजा वरुणोऽधिराजः। नक्षत्राणाᳲ शतभिषग्वसिष्ठः। तौ देवेभ्यः कृणुतो दीर्घमायुः। शतᳲ सहस्रा भेषजानि धत्तः। यज्ञन्नो राजा वरुण उपयातु। तन्नो विश्वे अभि संयन्तु देवाः। तन्नो नक्षत्रᳲ शतभिषग्जुषाणम्। दीर्घमायुः प्रतिरद्भेषजानि॥२४॥

(वरुणायस्वाहा शतभिषजे स्वाहा। भेषजेभ्यः स्वाहा।)

❖ पूर्व प्रोष्ठपदाः—अज एकपादुदगात्पुरस्तात्। विश्वा भूतानि प्रतिमोदमानः। तस्य देवाः प्रसवं यन्ति सर्वे। प्रोष्ठपदासो अमृतस्य गोपाः। विभ्राजमानस्समिधा न उग्रः। आऽन्तरिक्षम-

In Public domain. Digitization Muthulakshmi Research Academy

रुहद्गन्ध्याम्। तꣳ सूर्यं देवमजमेकपादम्। प्रोष्ठपदासो अनुयन्ति सर्वे॥२५॥

(अजायैकपदे स्वाहा प्रोष्ठपदेभ्यः स्वाहा।
तेजसे स्वाहा ब्रह्मवर्चसाय स्वाहा।)

❖ उत्तर प्रोष्ठपदाः—अहिर्बुध्नियः प्रथमान एति। श्रेष्ठो देवानामुत मानुषाणाम्। तं ब्राह्मणास्सोमपास्सोम्यासः। प्रोष्ठ-पदासो-अभिरक्षन्ति सर्वे। चत्वार एकमभि कर्म देवाः। प्रोष्ठ-पदा स इति यान् वदन्ति। ते बुध्नियं परिषद्यꣳ स्तुवन्तः। अहिꣳ रक्षन्ति नमसोपसद्य॥२६॥

(अहये बुध्नियाय स्वाहा प्रोष्ठपदेभ्यः स्वाहा।
प्रतिष्ठायै स्वाहा।)

❖ रेवतीः—पूषा रेवत्यन्वेति पन्थाम्। पुष्टिपती पशुपा वाजबस्त्यौ। इमानि हव्या प्रयताजुषाणा। सुगैर्नोयानैरुपयातां यज्ञम्। क्षुद्रान् पशून् रक्षतु रेवती नः। गावो नो अश्वाꣳ अन्वेतु पूषा। अन्नꣳ रक्षन्तौ बहुधा विरूपम्। वाजꣳ सनुतां यजमानाय यज्ञम्॥२७॥

(पूष्णे स्वाहा रेवत्यै स्वाहा। पशुभ्यः स्वाहा।)

❖ अश्विनीः—तदश्विनावश्वयुजोपयाताम्। शुभंगमिष्ठौ सुयमेभिरश्वैः। स्वं नक्षत्रꣳ हविषा यजन्तौ। मध्वासंपृक्तौ यजुषा समक्तौ। यौ देवानां भिषजौ हव्यवाहौ। विश्वस्य दूतावमृतस्य गोपौ। तौ नक्षत्रं जुजुषाणोपयाताम्। नमोऽश्विभ्यां कृणुमो-ऽश्वयुग्भ्याम्॥ २८॥

In Public domain. Digitization Muthulakshmi Research Academy

(अश्विभ्याꣳ स्वाहाऽश्व युग्भ्याꣳ स्वाहा।
श्रोत्राय स्वाहा श्रुत्यै स्वाहा॥)

❖ अपभरणीः—अप पाप्मानं भरणीर्भरन्तु। तद्यमो राजा भगवान् विचष्टाम्। लोकस्य राजा महतो महान् हि। सुगं नः पन्थामभयं कृणोतु। यस्मिन्नक्षत्रे यम एति राजा। यस्मिन्नेन-मभ्यषिंचन्त देवाः। तदस्य चित्रꣳ हविषा यजाम। अप पाप्मानं भरणीर्भरन्तु॥२९॥

(यमाय स्वाहाऽपभरणीभ्य स्स्वाहा।
राज्याय स्वाहाऽभिजित्यै स्वाहा॥)

❖ अमावास्याः—निवेशनी संगमनी वसूनां विश्वा रूपाणि वसून्यावेशयन्ती। सहस्र पोषꣳ सुभगा रराणा सा न आगन्वर्चसा संविदाना। यत्ते देवा अदधुर्भागधेयममावास्ये संवसन्तो महित्वा। सा नो यज्ञं पिपृहि विश्ववारे रयिन्नो धेहि सुभगे सुवीरम्॥ ३०॥

(अमावास्यायै स्वाहा कामाय स्वाहा गत्यै स्वाहा॥)

॥ शान्तिपञ्चकम् ॥

शं नो मित्रः शं वरुणः। शं नो भवत्वर्यमा। शं न इन्द्रो बृहस्पतिः। शं नो विष्णुरुरुक्रमः। नमो ब्रह्मणे। नमस्ते वायो। त्वमेव प्रत्यक्षं ब्रह्मासि। त्वमेव प्रत्यक्षं ब्रह्म वदिष्यामि। ऋतं वदिष्यामि। सत्यं वदिष्यामि। तन्मामवतु। तद्वक्तारमवतु। अवतु माम्। अवतु वक्तारम्॥

ॐ शान्तिः शान्तिः शान्तिः॥१॥

In Public domain. Digitization Muthulakshmi Research Academy

शं नो मित्रः शं वरुणः। शं नो भवत्वर्यमा। शं न इन्द्रो बृहस्पतिः। शं नो विष्णुरुरुक्रमः। नमो ब्रह्मणे। नमस्ते वायो। त्वमेव प्रत्यक्षं ब्रह्मासि। त्वामेव प्रत्यक्षं ब्रह्मावादिषम्। ऋतमं वादिषम्। सत्यमं वादिषम्। तन्मामावीत्। तद्वक्तारमावीत्। आवीन्माम्। आवीद्वक्तारम्॥

ॐ शान्तिः शान्तिः शान्तिः॥२॥

सहनाववतु। सह नौ भुनक्तु। सह वीर्यं करवावहै। तेजस्विनावधीतमस्तु मा विद्विषावहै॥

ॐ शान्तिः शान्तिः शान्तिः॥३॥

ॐ नमो वाचे या चोदिता या चानुदिता तस्यै वाचे नमो नमो वाचे नमो वाचस्पतये नम ऋषिभ्यो मन्त्रकृद्भ्यो मन्त्रपतिभ्यो मामामृषयो मन्त्रकृतो मन्त्रपतयः परादुर्माऽह-मृषीन्मन्त्रकृतो मन्त्रपतीन्परादां वैश्वदेवीं वाचमुद्यासं शिवाम-दस्तांजुष्टां देवेभ्यः शर्म मे द्यौः शर्म पृथिवी शर्म विश्वमिदं जगत्। शर्म चन्द्रश्च सूर्यश्च शर्म ब्रह्मप्रजापती। भूतं वदिष्ये भुवनं वदिष्ये तेजो वदिष्ये यशो वदिष्ये तपो वदिष्ये ब्रह्म वदिष्ये सत्यं वदिष्ये तस्मा अहमिदमुपस्तरण-मुपस्तृण उपस्तरणं मे प्रजायै पशूनां भूयादुपस्तरणमहं प्रजायै पशूनां भूयासं प्राणापानौ मृत्योर्मा पातं प्राणापानौ मा माहासिष्टं मधु मनिष्ये मधु जनिष्ये मधु वक्ष्यामि मधु वदिष्यामि मधुमतीं देवेभ्यो वाचमुद्यासं शुश्रूषेण्यां मनुष्येभ्यस्तं मा देवा अवन्तु शोभायै पितरोऽनुमदन्तु॥४॥

ॐ शान्तिः शान्तिः शान्तिः॥

ॐ तच्छं योरावृणीमहे। गातुं यज्ञाय। गातुं यज्ञपतये। दैवी

In Public domain. Digitization Muthulakshmi Research Academy

स्वस्तिरस्तु नः। स्वस्तिर्मानुषेभ्यः। ऊर्ध्वं जिगातु भेषजम्। शं नो अस्तु द्विपदे। शं चतुष्पदे॥५॥

ॐ शान्तिः शान्तिः शान्तिः॥

आभिर्गीर्भिर्यदतोन ऊनमाप्यायय हरिवो वर्द्धमानः। यदास्तोतृभ्यो महिं गोत्रा रुजासि भूयिष्ठभाजो अध ते स्याम। ब्रह्म प्रावादिष्म तन्नो मा हासीत्॥

ॐ शान्तिः शान्तिः शान्तिः॥

॥ सरस्वती सूक्तम् ॥

प्रणो देवी सरस्वती वाजेभिर्वाजिनीवती। धीनामवित्र्यवतु॥१॥

आनो दिवो बृहतः पर्वतादा सरस्वती यजता गन्तु यज्ञम्। हवन्देवी जुजुषाणा घृताची शग्मान्नो वाचमुशती शृणोतु॥२॥

पावीरवी कन्या चित्रायुस्सरस्वती वीरपत्नी धियन्धात्। ग्नाभिरच्छिद्रꣳ शरणꣳसजोषा दुराधर्षं ङ्गृणते शर्म यꣳसत्॥३॥

इमा जुह्वाना युष्मदा नमोभिः। प्रति स्तोमꣳसरस्वति जुषस्व। तव शर्मन् प्रियतमे दधानाः। उपस्थेयाम शरणन्न वृक्षम्॥४॥

यस्तेस्तनश्शशयो यो मयो भूः। येन विश्वा पुष्यसि वार्याणि। यो रत्नधा वसुविद्यः सुदत्रः। सरस्वति तमिह धातवेकः॥५॥

सरस्वत्यभिनो नेषि वस्यः। मापस्फरीः पयसा मा न आ धक्। जुषस्वनस्सख्या वेश्या च। मात्वत् क्षेत्राण्यरणानि गन्म॥६॥

इयꣳशुष्मेभिर्बिसखा इवारुजत्। सानु गिरीणान्त-

In Public domain. Digitization Muthulakshmi Research Academy

विषेभिरूर्मिभिः। पारावदघ्नीमवसे सुवृक्तिभिः। सरस्वतीमा विवासेम धीतिभिः ॥७॥

॥ इति सरस्वतीसूक्तं समाप्तम् ॥

॥ त्रिसुपर्ण मन्त्राः ॥

ब्रह्म मेतु माम्। मधु मेतु माम्। ब्रह्म मेव मधु मेतु माम्। यास्ते सोम प्रजावथ्सोभिसो अहम्। दुष्वप्नहन्दुरुष्षह। यास्ते सोम प्राणाᳪं स्ताञ्जुहोमि। त्रिसुपर्ण मयाचितं ब्राह्मणाय दद्यात्। ब्रह्महत्याँ व्वाएतेघ्नन्ति। ये ब्राह्मणास्त्रिसुपर्णं पठन्ति। ते सोमं प्राप्नुवन्ति। आसहस्रात्पङ्क्तिं पुनन्ति। ओम्॥१॥

ब्रह्म मेधया। मधु मेधया। ब्रह्ममेव मधु मेधया। अद्या नो देव सवितः प्रजावथ्सावीस्सौभगम्। परा दुष्वप्नियᳪंसुव। विश्वानि देव सवितर्दुरितानि परासुव। यद्भद्रन्तन्म आसुव। मधुवाता ऋतायते मधुक्षरन्ति सिन्धवः। माद्ध्वीर्नस्सन्त्वोषधीः। मधुनक्तमुतोषसि मधुमत्पार्थिवᳪंरजः। मधुद्यौरस्तु नः पिता। मधुमान्नो वनस्पतिर्मधुमाᳪं अस्तु सूर्यः। माद्ध्वीर्गावो भवन्तु नः। य इमन्त्रिसुपर्णमयाचितं ब्राह्मणाय दद्यात्। भ्रूणहत्याँव्वा एतेघ्नन्ति। ये ब्राह्मणास्त्रिसुपर्णं पठन्ति। ते सोमं प्राप्नुवन्ति। आसहस्रात्पङ्क्तिं पुनन्ति। ओम्॥२॥

ब्रह्म मेधवा। मधु मेधवा। ब्रह्म मेव मधु मेधवा। ब्रह्मा देवानां पदवीः कवीनामृषिर्विप्राणां महिषो मृगाणाम्। श्येनो गृद्ध्राणाᳪं स्वधितिर्वनानाᳪं सोमः पवित्रमत्येतिरेभन्न्। हᳪंसश्शुचिषद्वसुरन्तरिक्षसद्धोतावेदिष दतिथिर्दुरोणसत्। नृषद्वरसदृतसद्व्योम सदब्जा गोजा ऋतजा अद्रिजा ऋतं बृहत्।

In Public domain. Digitization Muthulakshmi Research Academy

ऋचेत्वा रुचेत्वा समिथ्स्त्रवन्ति सरितो न धेनाः। अन्तर् हृदा मनसा पूयमानाः। घृतस्य धारा अभिचाकशीमि। हिरण्ययो वेतसो मद्ध्य आसाम्। तस्मिन्थ्सुपर्णो मधुकृत्कुलायी भजन्नास्ते मधु देवताभ्यः। तस्यासते हरयस्सप्ततीरे स्वधान्दुहाना अमृतस्य धाराम्। य इदन्त्रिसुपर्णमयाचितं ब्राह्मणाय दद्यात्। वीरहत्यांव्वा एतेघ्नन्ति। ये ब्राह्मणास्त्रिसुपर्णं पठन्ति। ते सोमं प्राप्नुवन्ति। आसहस्त्रात्पङ्क्तिं पुनन्ति॥ओम्॥३॥

ॐ शान्तिः शान्तिः शान्तिः॥

॥ घृत सूक्तम्॥

१. समिधाऽग्निन्दुवस्यत। घृतै र्बोधयतातिथिम्। आस्मिन् हव्या जुहोतन॥ (सं. 4-2-3)

२. उपत्वाऽग्ने हविष्मतीः। घृताचीर्यन्तु हर्यत। जुषस्वँ समिधो मम॥ (ब्रा. 1.2.1)

३. तन्त्वा समिद्भिरङ्गिरः। घृतेन वर्द्धयामसि। बृहच्छो चा यविष्ठ्य॥

४. समिद्ध्यमानः प्रथमोनु धर्मः। समक्तुभिरज्यते विश्ववारः। शोचिष्केशो घृत निर्णिक्पावकः। सुयज्ञो अग्नि र्यजथाय देवान्॥

५. घृत प्रतीको घृत योनि रग्निः। घृतै स्समिद्धो घृतमस्यान्नम्। घृत प्रुषस्त्वा सरितो वहन्ति। घृतं पिबन्थ्सु यजा यक्षि देवान्॥

६. आयुर्दा अग्ने हविषो जुषाणः। घृत प्रतीको घृत योनि रेधि। घृतं पीत्वा मधु चारुगव्यम्। पितेव पुत्र मभि रक्षता दिमम्॥

In Public domain. Digitization Muthulakshmi Research Academy

॥ मृत्यु सूक्तम् ॥

(अपवा एतस्मात्)

अपवा एतस्माच्छ्री राष्ट्रङ्क्रामति। यो॑ऽश्व मेधेन यजते। ब्राह्मणौ वींणा गाथिनौ गायतः। श्रिया वा एत द्रूपम्। यद् वीणा॑ः। श्रिय मेवास्मिन्तद्धत्तः। यदा खलु वै पुरुष श्श्रियं मश्नुते। वीणा॑ऽस्मै वाद्यते। तदा॑हुः। यदुभौ ब्रा॑ह्मणौ गायेताम्॥ प्रभ्र॑ंशुकाऽस्माच्छ्री स्स्या॑त्। नवै ब्रा॑ह्मणे श्री रमत इति। ब्राह्मणौ॑ऽन्यो गाये॑त्। राजन्यो॑ऽन्यः। ब्रह्मवै ब्रा॑ह्मणः। क्षत्रं राजन्यः। तथा हास्य ब्रह्मणा च क्षत्रेण चोभयत श्श्रीः परि गृहीता भवति। तदाहुः। यदुभौ दिवा गायेताम्। अपा॑स्मा द्राष्ट्रं क्रामेत्॥ नवै ब्रा॑ह्मणे राष्ट्रंरमत इति। यदा खलु वै राजा कामयते। अथ ब्राह्मण ञ्जिनाति। दिवा॑ ब्राह्मणो गायेत्। नक्तं राजन्यः। ब्रह्मणो वै रूप महः। क्षत्रस्य रात्रिः। तथा हास्य ब्रह्मणा च क्षत्रेण चोभयतौ राष्ट्रं परि गृहीतं भवति। इत्य ददा इत्य यजथा इत्य पच इति ब्राह्मणो गाये॑त्। इष्टा पूर्तं वै ब्रा॑ह्मणस्य॥ इष्टा पूर्ते नैवैनंस समर्द्ध यति। इत्यजिना इत्य युद्ध्यथा इत्यमुंसंग्राम महन्निति राजन्यः। युद्धं वै राजन्यस्य। युद्धे नैवैनंस समर्द्धयति। अक्लृप्तावा एत स्यर्तव इत्याहुः। यो॑ऽश्व मेधेन यजत इति। तिस्रो॑ऽन्यो गायति तिस्रो॑न्यः। षट् थ्संपद्यन्ते। षड्वा ऋतवः। ऋतू नेवास्मै॑ कल्पयतः। ताभ्यां स ं स्थाया॑म्। अनो युक्ते च शते च ददाति। शतायुः पुरुष श्शतेन्द्रियः। आयुष्येवेन्द्रिये प्रतितिष्ठति॥

In Public domain. Digitization Muthulakshmi Research Academy

॥ आयुष्य सूक्तम् ॥

१. यो ब्रह्मा ब्रह्मण उज्जहार प्राणैश्शिरःकृत्तिवासाः पिनाकी। ईशानो देवस्सन आयु र्दधातु तस्मै जुहोमि हविषा घृतेन॥

२. विभ्राजमानः सरि रस्य मद्ध्या द्रोचमानो घर्म रुचिर्य आगात्। समृत्यु पाशा नप नुद्य घोरा निहायुषेणो घृत मत्तु देवः॥

३. ब्रह्म ज्योति र्ब्रह्म पत्नीषु गर्भं यमा दधात्पुरुरूपं जयन्तम्। सुवर्ण रंभ ग्रह मर्क मर्च्यं तमायुषे वर्ध यामो घृतेन॥

४. श्रियं लक्ष्मी मौबला मंबिकां गां षष्ठीञ्च यामिन्द्र सेनेत्यु दाहुः। तां विद्यां ब्रह्म योनिꣳ सरूपा मिहायुषे तर्पयामो घृतेन॥

५. दाक्षायण्यः सर्व योन्यः सुयोन्यः सहस्त्रशो विश्व रूपा विरूपाः। ससूनवः सपतयः सयूथ्या आयुषेणो घृतमिदं जुषन्ताम्॥

६. दिव्या गणा बहुरूपाः पुराणा आयुश्छिदोनः प्रमथ्नन्तु वीरान्। तेभ्यो जुहोमि बहुधा घृतेन मा नः प्रजाꣳ रीरिषो मोत वीरान्॥

७. एकः पुरस्ता द्य इदं बभूव यतो बभूव भुवनस्य गोपाः। यमप्येति भुवनꣳसाम्पराये सनो हविर्घृत मिहायुषेऽत्तु देवः॥

८. वसून्रुद्रा नादित्यान् मरुतोऽथ साद्ध्यानृभून् यक्षान् गन्धर्वा-ꣳश्च पितॄꣳश्च विश्वान्। भृगून्थ्सर्पाꣳश्चा ङ्गिरसोऽथ सर्वान् घृतꣳहुत्वा स्वायुष्या महयाम शश्वत्॥

विष्णो त्वन्नो अन्तम शशर्म यच्छ सहन्त्य। प्रते धारा मधुश्चुत उथ्सन्दुह्रते अक्षितम्॥ आभिर्गीर्भि र्यदतो न ऊन

In Public domain. Digitization Muthulakshmi Research Academy

माप्यायय हरिवो वर्द्धमानः। यदास्तो तृभ्यो महिं गोत्रा रुजासिं भूयिष्ठ भाजो अधते स्याम। ब्रह्म प्रावा दिष्म तन्नो माहासीत्॥
ओं शान्तिः शान्तिः शान्तिः॥

॥ घोष शान्तिः॥

शन्नो वातः पवतां मातरिश्वा शन्न स्तपतु सूर्यः। अहानि शंभवन्तु न श्श ँरात्रिः प्रति धीयताम्। शमुषानो व्युच्छतु शमादित्य उदेतु नः। शिवान् श्शन्तमा भव सुमृडीका सरस्वति। माते व्योम सन्दृशि। इडायै वास्त्वसि वास्तु मद्वास्तु मन्तो भूयास्ममा वास्तों शिछथ्स्मह्य वास्तुस्सभूयाद्योऽस्मान्द्वेष्टि यञ्च वयन्द्विष्मः। प्रतिष्ठाऽसि प्रतिष्ठा वन्तो भूयास्म मा प्रतिष्ठाया शिछथ्स्मह्य प्रतिष्ठ स्सभूया द्योऽस्मान्द्वेष्टि यञ्च वयन्द्विष्मः। आवात वाहि भेषजं विवात वाहि यद्रपः। त्व ँ हि विश्व भेषजो देवानान्दूत ईयसे। द्वा विमौ वातौ वात आसिन्धोरा परावतः॥१॥ दक्षं मे अन्य आवातु पराऽन्यो वातु यद्रपः। यद्दो वात ते गृहेऽमृतस्य निधिर् हितः। ततो नो देहि जीवसे ततो नो धेहि भेषजम्। ततो नो मह आवह वात आवातु भेषजम्। शंभू मयो भू नों हृदे प्रण आयू ँ षि तारिषत्। इन्द्रस्य गृहोऽसि तन्त्वा प्रपद्ये सगुस्साश्वः। सह यन्मे अस्ति तेन। भूः प्रपद्ये भुवः प्रपद्ये सुवः प्रपद्ये भू र्भुव स्सुवः प्रपद्ये वायुं प्रपद्येऽनार्ता न्देवतां प्रपद्येऽश्मानमा खणं प्रपद्ये प्रजापते र्ब्रह्म कोशं ब्रह्म प्रपद्य ओं प्रपद्ये। अन्तरिक्षं म उर्वन्तरं बृहदग्नयः पर्वताश्च यया वात स्स्वस्त्या स्वस्तिमा न्तया स्वस्त्या स्वस्ति मानसानि। प्राणापानौ मृत्योर्मा पातं प्राणा पानौ मामाहा सिष्टं मयि मेधां मयि प्रजां मय्यग्नि स्तेजो दधातु मयि

In Public domain. Digitization Muthulakshmi Research Academy

मेधां मयिप्रजां मयीन्द्रं इन्द्रियं दधातु मयि मेधां मयि प्रजां मयि सूर्यो भ्राजो दधातु ॥ २ ॥

द्युभि रक्तुभिः परिपात मस्मा नरिष्टेभि रश्विना सौभगेभिः। तन्नो मित्रो वरुणो मामहन्ता मदिति स्सिन्धुः पृथिवी उतद्यौः। कयान श्चित्र आभुव दूती सदावृधस्सखा। कया शचिष्ठया वृता॥ कस्त्वा सत्यो मदानां मꣳहिष्ठोम थ्सदन्धसः। दृढ़ा चिदा रुजे वसु। अभीषुणः सखी ना मविता जरितॄणाम्। शतं भवा स्यूतिभिः। वयस्सुपर्णा उपसेदु रिन्द्रं प्रिय मेधा ऋषयो नाधमानाः। अपद्ध्वा न्तमूर्णुहि पूर्द्धि चक्षु र्मुमुग्ध्यस्मा न्निधयेव बद्धान् ॥ ३ ॥

शन्नो देवी रभिष्टय आपो भवन्तु पीतये। शं यो रभिस्त्र वन्तु नः। ईशाना वार्याणाङ् क्षयन्ती श्चर्षणीनाम्। अपो याचामि भेषजम्। सुमित्रान आप ओषधय स्सन्तु दुर्मित्रा स्तस्मै भूयासुर्यो ऽस्मान्द्वेष्टि यञ्च वयन्द्विष्मः। आपोहिष्ठा मयोभुव स्तान ऊर्जे दधातन। महेरणाय चक्षसे। यो व शिशवतमो रस स्तस्य भाजयते हनः। उशतीरिव मातरः। तस्मा अरङ्ग मामवो यस्य क्षयाय जिन्वथ ॥ ४ ॥

आपो जनयथा च नः॥ पृथिवी शान्ता साऽग्निना शान्ता सा मे शान्ता शुच ꣳ शमयतु। अन्तरिक्ष ꣳ शान्तन्तद्वायुना शान्तन्तन्मे शान्त ꣳ शुचꣳ शमयतु। द्यौश्शान्ता साऽऽदित्येन शान्ता सामे शान्ता शुचꣳ शमयतु। पृथिवी शान्ति रन्तरिक्ष ꣳशान्ति द्यौश्शान्ति दिश श्शान्ति रवान्तर दिशा श्शान्ति रग्नि श्शान्ति र्वायुश्शान्ति रादित्य श्शान्ति श्चन्द्रमा श्शान्ति र्नक्षत्राणि शान्ति राप श्शान्ति रोषधय श्शान्ति र्वनस्पतय श्शान्ति

In Public domain. Digitization Muthulakshmi Research Academy

गौं श्शान्ति रजा शान्ति रश्वश्शान्तिः पुरुष श्शान्ति ब्रंह्म शान्ति ब्राँह्मण श्शान्ति श्शान्ति रेव शान्ति श्शान्ति में अस्तु शान्तिः। तयाऽहं॑ शान्त्या सर्व शान्त्या मह्यंन्द्विपदे चतुंष्पदे च शान्ति ङ्करोमि शान्ति में अस्तु शान्तिः। एह श्रीश्च ह्रीश्च धृतिश्च तपो मेधा प्रतिष्ठा श्रद्धा सत्य न्धर्म श्चैतानि मोत्तिष्ठन्त मनूत्तिष्ठन्तु मा मा॑ं॑ श्रीश्च ह्रीश्च धृतिश्च तपो मेधा प्रतिष्ठा श्रद्धा सत्यन्धर्म श्चैतानि मा माहा सिषुः। उदायुंषा स्वायुषो दोषधी ना ं॑ रसेनो त्पर्जन्यस्य शुष्मेणो दस्था ममृता ं॑ अनु। तच्चक्षु र्देवहितं पुरस्ता च्छुक्र मुच्चरत्। पश्येम शरदं श्शत ञ्जीवेम शरदश्शतन्नन्दाम शरदश्शतं मोदाम शरदश्शतं भवाम शरदश्शतं॑ शृणवाम शरदश्शतं प्रब्रवाम शरदश्शत मजीतास्स्याम शरदश्शत ञ्ज्योक्च सूर्यन्दृशे॥५॥

य उदगा न्महतोऽर्णवा द्विभ्राजमान स्सरिरस्य मद्ध्याथ्समा वृषभो लोहिताक्ष स्सूर्यो विपश्चिन्मनसा पुनातु। ब्रह्मण- श्चोतन्यसि ब्रह्मण आणीस्थो ब्रह्मण आवपन मसि धारितेयं पृथिवी ब्रह्मणा मही धारित मेनेन महदन्तरिक्षन्दिव न्दाधार पृथिवी ं॑ स देवां यदहं वेद तदह न्धारयाणि माम द्वेदोऽधि विस्रसत्। मेधा मनीषे मा विशता॑ंसमीची भूतस्य भव्य स्यावरुद्ध्यै सर्व मायुरयाणि सर्व मायुरयाणि॥ आभि गीर्भि र्यदतोन ऊनमाप्प्या यय हरिवो बर्द्धमानः। यदा स्तो तृभ्यो महि गोत्रा रुजासि भूयिष्ठ भाजो अधतेस्याम । ब्रह्म प्रावा दिष्म तन्नो माहासीत्॥ ओं शान्तिः शान्तिः शान्तिः॥६॥

नमो ब्रह्मणे नमो अस्त्वग्नये नमः पृथिव्यै नम ओषधीभ्यः। नमो वाचे नमो वाचस्पतये नमो विष्णवे बृहते करोमि॥(त्रिः॥)

In Public domain. Digitization Muthulakshmi Research Academy

॥ उदकशान्तिः ॥

॥ हरिः ओम् ॥

अग्निमीळे पुरोहितं यज्ञस्य देवमृत्विजम्। होतारं रत्नधातमम्॥ इषेत्वोर्जे त्वा वायवस्स्थो पायवस्स्थ देवो वस्सविता प्रार्पयतु श्रेष्ठतमाय कर्मणे॥ अग्न आयाहि वीतये गृणानो हव्यदातये। निहोता सत्सि बर्हिषि॥ शन्नो देवीरभिष्टय आपो भवन्तु पीतये। शंयोरभिस्रवन्तु नः ॥१॥

कृणुष्व पाजः प्रसितिन्न पृथ्वीं याहि राजे वामवाꣳ इभेन। तृष्वीमनु प्रसितिं द्रूणानोऽस्ताऽसि विद्ध्यरक्षसस्तपिष्ठैः। तवभ्रमास आशु या पतन्त्यनुस्पृश धृषता शोशुचा नः। तपूꣳष्यग्ने जुह्वा पतंगानसन्दितो विसृजविष्व गुल्काः। प्रतिस्पशो विसृजतूर्णि तमो भवा पायुर्विशो अस्या अदब्धः। यो नो दूरे अघशꣳसः सो यो अन्त्यग्ने माकिष्टे व्यथिरादधर्षीत्। उदग्ने तिष्ठ प्रत्यातनुष्वन्यमित्राꣳ ओषतात्तिग्महेते। यो नो अरातिꣳ समिधानचक्रे नीचातन्धक्ष्यत सन्नशुष्कम्। ऊर्ध्वो भव प्रतिविद्ध्याद्ध्यस्मदाविष्कृणुष्व दैव्यान्यग्ने। अवस्थिरा तनुहि यातु जूनां जामिमजामिं प्रमृणीहि शत्रून्। स ते जानाति सुमतिं यविष्ठय ईवते ब्रह्मणे गातुमैरत्। विश्वान्यस्मै सुदिना निरायो द्युम्नान्यर्यो विदुरो अभिद्यौत्। सेदग्ने अस्तु सुभगस्सुदानुर्यस्त्वा नित्येन हविषा य उक्थैः। पिप्रीषतिस्व आयुषि दुरोणे विश्वेदस्मै सुदिनासाऽसदिष्टिः। अर्चामि ते सुमतिं घोष्यर्वाक् सन्ते वा वाता जरता मियंगीः। स्वश्वास्त्वा सुरथामर्जये मास्मेक्षत्राणि धारयेरनुद्यून्। इह त्वा भूर्याचरे दुपत्मन्दोषावस्तर्दी दिवाꣳ समनुद्यून्। क्रीडन्तस्त्वा सुमनसस्सपेमाभिद्युम्ना तस्थिवाꣳ सो जनानाम्। यस्त्वास्वश्वस्सु हिरण्यो अग्न उपयाति वसुमता रथेन। तस्य त्राता भवसि तस्य

In Public domain. Digitization Muthulakshmi Research Academy

सखा यस्ते आतिथ्य मानुषग्जुजौषत्। महोरुजामि। बन्धुता बचौभिस्तन्मा पितुर्गोतमादन्वियाय। त्वन्नो अस्य वचसश्चिकिद्धि होतर्यविष्ठ सुक्रतो दमूनाः। अस्वप्नजस्तरणय स्सुशेवा अतन्द्रासोऽवृका अश्रमिष्ठाः। ते पायवस्सध्रियञ्चो निषद्याग्ने तव नः पान्त्वमूर। ये पायवो मामतेयन्ते अग्ने पश्यन्तो अन्धन्दुरिता-दरक्षन्। ररक्षतान् सुकृतो विश्ववेदादिप्सन्त इद्रिपवो नाह देभुः। त्वया वयः सधन्यस्त्वोतास्तव प्रणीत्य श्याम वाजान्। उभा शंसा सूदय सत्यता तेऽनुष्ठुया कृणुह्यह्रयाण। अया ते अग्ने समिधा विधेम प्रतिस्तोमं शस्यमानं गृभाय। दहाशसो रक्षसः पाह्यस्मान्द्रुहो निदो मित्रमहो अवद्यात्। रक्षोहणं वाजिनमाजि घर्मि मित्रं प्रथिष्ठमुपयामि शर्म। शिशानो अग्निः क्रतुभि स्समिद्धस्सनो दिवा सरिषः पातु नक्तम्। विज्योतिषा बृहता भात्यग्निराविर्विश्वानि कृणुते महित्वा। प्रादेवीर्माया स्सहते दुरेवा शिशीते श्रृंगे रक्षसे विनिक्षे। उतस्वानासो दिविषन्त्वग्ने स्तिग्मायुधा रक्षसे हन्त वा उ॥२॥

इन्द्रं वो विश्वतस्परि हवामहे जनेभ्यः। अस्माकमस्तु केवलः। इन्द्रन्नरो नेमधिता हवन्ते यत्पार्या युनजते धियस्ताः। शूरो नृषाता शवसश्चका न आगोमतिव्रजे भजा त्वन्नः। इन्द्रियाणि शतक्रतो याते जनेषु पंचसु। इन्द्रतानित आवृणे। अनुते दायि मह इन्द्रियाय सत्राते विश्वमनु वृत्रहत्ये। अनु क्षत्रमनु सहो यजत्रेन्द्र देवेभिरनुते नृषह्ये। आयस्मिन् सप्तवासवास्तिष्ठन्ति स्वारुहो यथा। ऋषिर्ह दीर्घश्रुत्तम इन्द्रस्य घर्मो अतिथिः। आमासु पक्व-मैरय आसूर्यं रोहयो दिवि। घर्मन्न सामन्तपता सुवृक्तिभिर्जुष्टं गिर्वणसे गिरः। इन्द्रमिद्गाथिनो बृहदिन्द्रमर्केभिरर्किणः। इन्द्रं वाणीरनूषत। गायन्ति त्वा गायत्रिणोऽर्चन्त्यर्कमर्किणः।

In Public domain. Digitization Muthulakshmi Research Academy

ब्रह्माणस्त्वा शतक्रतवुद्वꣳ शमिव येमिरे। अꣳहो मुचे प्रभरेमा-मनीषा मौषिष्ठुदाव्न्ने सुमतिं गृणानाः। इदमिन्द्र प्रति हव्यंगृभाय सत्या स्सन्तु यजमानस्य कामाः। विवेषयन्मा धिषणा जजानस्तवै पुरा पार्यादिन्द्रमह्नः। अꣳहसो यत्र पीपरद्यथा नो नावेव यान्तमु-भयै हवन्ते। प्रसम्राजं प्रथममध्वराणाम ꣳ हो मुचं वृषभं यज्ञिया-नाम्। अपान्नपातमश्विना हयन्तमस्मिन्नर इन्द्रियं धत्तमोजः। विन इन्द्रमृधो जहिनीचा यच्छ पृतन्यतः। अधस्पदन्त मीं कृधियो अस्माꣳ अभिदासति। इन्द्रक्षत्रमभिवाम मोजोऽजायथा वृषभ-चर्षणीनाम्। अपानुदो जनममित्र यन्त मुरुं देवेभ्यो अकृणोरु लोकम्। मृगो न भीमः कुचरो गिरिष्ठाः परा वत आजगामा-परस्याः। सृकꣳसꣳशाय पविमिन्द्र तिग्मं विशत्रून्ताढि विमृधोनु-दस्व। विशत्रून् विमृधो नुद विवृत्रस्य हनूरुज। विमन्युमिन्द्र भामितोऽमित्रस्याभिदासतः। त्रातारमिन्द्र मवितारमिन्द्रꣳ हवे हवे सुहवꣳ शूरमिन्द्रम्। हुवे नु शक्रं पुरुहूतमिन्द्रꣳ स्वस्ति नो मघवा धात्विन्द्रः। मा तै अस्या ꣳ सहसा वन्परिष्टा वघाय भूमहरिवः परादै। त्रायस्व नोऽवृकेभिर्वरूथैस्तव प्रियासस्सूरिषु स्याम। अनवस्ते रथमश्वाय तक्षन्त्वष्टा वज्रं पुरुहूत द्युमन्तम्। ब्रह्माण इन्द्रं महयन्तो अर्कैरवर्द्धयन्न हये हन्त वा उ। वृष्णे यत्ते वृषणो अर्कमर्चा निन्द्र ग्रावाणो अदिति स्सजोषाः। अनश्वासो ये पवयोऽरथा इन्द्रेषिता अभ्यवर्तन्त दस्यून्॥३॥

यत इन्द्र भयामहे ततो नो अभयं कृधि। मघवञ्छग्धि तव तन्न ऊतये विद्विषो विमृधो जहि। स्वस्तिदा विशस्पतिर्वृत्रहा विमृधो वशी। वृषेन्द्रः पुर एतु नः स्वस्तिदा अभयंकरः॥ महाꣳ इन्द्रो वज्रबाहुः षोडशी शर्म यच्छतु। स्वस्ति नो मघवा करोतु हन्तु पाप्मानं योऽस्मान् द्वेष्टि॥ सजोषा इन्द्र सगणो मरुद्भिस्सोमं पिब

In Public domain. Digitization Muthulakshmi Research Academy

वृत्रहञ्छूरविद्वान्। जहि शत्रू२ँरपमृधौनुदस्वाथा भयं कृणु हि विश्वतौ नः ॥४॥

ये देवाः पुरस्सदोऽग्नि ने॑त्रा रक्षोहणस्तेनेः पान्तु ते नौऽवन्तु तेभ्यो नमस्तेभ्यः स्वाहा, ये देवा दक्षिणसदौ यमने॑त्रा रक्षोहणस्तेनेः पान्तुः ते नौऽवन्तु तेभ्यो नमस्तेभ्यः स्वाहा, ये देवाः पश्चात् सदस्सवितृ ने॑त्रा रक्षोहणस्तेनेः पान्तु ते नौऽवन्तु तेभ्यो नमस्तेभ्यः स्वाहा, ये देवा उत्तरसदो वरुणनेत्रा रक्षोहणस्ते नेः पान्तु ते नौऽवन्तु तेभ्यो नमस्तेभ्यः स्वाहा, ये देवा उपरिषदो बृहस्पतिनेत्रा रक्षोहणस्ते नेः पान्तु ते नौऽवन्तु तेभ्यो नमस्तेभ्यः स्वाहाऽग्नये रक्षोघ्ने स्वाहा यमाय रक्षोघ्ने स्वाहा सवित्रे रक्षोघ्ने स्वाहा वरुणाय रक्षोघ्ने स्वाहा बृहस्पतये दुवस्वते रक्षोघ्ने स्वाहा॑ ॥ ५ ॥

अग्निरायुष्मान्थ्सवनस्पतिभिरायुष्मान् तेन त्वाऽऽयुषा-ऽऽयुष्मन्तं करोमि सोम आयुष्मान्थ्स ओषधीभिरायुष्मान् तेन त्वाऽऽयुषा ऽऽयुष्मन्तं करोमि यज्ञ आयुष्मान्थ्स दक्षिणाभि-रायुष्मान् तेन त्वाऽऽयुषाऽऽयुष्मन्तं करोमि ब्रह्मायुष्मत्तद् ब्राह्मणै-रायुष्मत्तेन त्वाऽऽयुषा ऽऽयुष्मन्तं करोमि देवा आयुष्मन्तस्तै-ऽमृतेनायुष्मन्तस्तेन त्वा ऽऽयुषा ऽऽयुष्मन्तं करोमि ॥६॥

या वामिन्द्रा वरुणा यतव्या तनूस्त येमम२ँहसो मुञ्चतं यावामिन्द्रा वरुणा सहस्यातनूस्तयेमम२ँहसो मुंचतं यावामिन्द्रा वरुणा रक्षस्या तनूस्तयेमम२ँहसो मुंचतं यावामिन्द्रा वरुणा तेजस्या तनूस्तयेमम२ँहसो मुंचतं योवामिन्द्रा वरुणा वग्नौ स्त्रामस्तं वामेतेनावयजे योवामिन्द्रा वरुणा द्विपात्सु पशुषु स्त्रामस्तं वामेतेनावयजे योवामिन्द्रा वरुणा चतुष्पात्सु स्त्रामस्तं वा मेतेना-वयजे योवामिन्द्रा वरुणा गोष्ठे स्त्रामस्तं वा मेतेनावयजे यो

In Public domain. Digitization Muthulakshmi Research Academy

वामिन्द्रा वरुणा गृहेषु स्त्रामस्तं वामेतेनावयजे योवामिन्द्रा वरुणाऽप्सु स्त्रामस्तंवामेतेनावयजे योवामिन्द्रावरुणौषधीषु स्त्रामस्तंवामेतेनावयजे योवामिन्द्रावरुणा वनस्पतिषु स्त्रामस्तं वा मेतेनावयजे॥७॥

अग्ने यशस्विन् यशसे ममर्पयेन्द्रावती मपचितीमिहावह। अयं मूर्धा परमेष्ठी सुवर्चाँस्समानानामुत्तम श्लोको अस्तु॥ भद्रं पश्यन्त उपसेदुरग्रे तपो दीक्षामृषयस्सुवर्विदः। ततः क्षत्रं बलमोजश्च जातं तदस्मै देवा अभि सन्नमन्तु॥ धाता विधाता परमोतसन्दृक् प्रजापतिः परमेष्ठी विराजा। स्तोमाच्छन्दाꣳसि निविदो म आहुरेतस्मैं राष्ट्रमभि सन्नमाम॥ अभ्यावर्तध्वमुपमेतसाकमयꣳशास्ताऽधिपतिर्वोअस्तु। अस्य विज्ञान मनुसꣳ रभध्वमिमं पश्चादनु जीवाथ सर्वे॥८॥

ऋताषाडृतधामाऽग्निर्गन्धर्वस्तस्यौषधयोऽप्सरस ऊर्जो नाम स इदं ब्रह्म क्षत्रं पातु ता इदं ब्रह्म क्षत्रं पान्तु तस्मै स्वाहा ताभ्यः स्वाहा, सꣳहितो विश्वसामा सूर्यो गन्धर्व स्तस्य मरीचयोऽप्सरस आयुवो नाम स इदं ब्रह्मक्षत्रं पातु ता इदं ब्रह्म क्षत्रं पान्तु तस्मै स्वाहा ताभ्यः स्वाहा, सुषुम्नः सूर्यरश्मिश्चन्द्रमा गन्धर्वस्तस्य नक्षत्राण्यप्सरसो बेकुरयो नाम स इदं ब्रह्मक्षत्रं पातु ता इदं ब्रह्मक्षत्रं पान्तु तस्मै स्वाहा ताभ्यः स्वाहा, भुज्युः सुपर्णो यज्ञो गन्धर्वस्तस्य दक्षिणा अप्सरसः स्तवा नाम स इदं ब्रह्मक्षत्रं पातु ता इदं ब्रह्मक्षत्रं पान्तु तस्मै स्वाहा ताभ्यः स्वाहा, प्रजापति विश्वकर्मा मनो गन्धर्वस्तस्यर्क्सामान्यप्सरसो वह्नयो नाम स इदं ब्रह्मक्षत्रं पातु ता इदं ब्रह्मक्षत्रं पान्तु तस्मै स्वाहा ताभ्यः स्वाहेऽषिरो विश्वव्यचा वातो गन्धर्वस्तस्याऽऽपोऽप्सरसो मुदा नाम स इदं ब्रह्मक्षत्रं पातु ता इदं ब्रह्मक्षत्रं पान्तु तस्मै स्वाहा ताभ्यः स्वाहा,

In Public domain. Digitization Muthulakshmi Research Academy

भुवनस्य पते यस्य त उपरि गृहा इह च। स नो रास्वाज्यानिꣳ रायस्पोषꣳ सुवीर्यꣳ संवत्सरीणाꣳ स्वस्तिꣳ स्वाहा, परमेष्ठ्यधिपति- र्मृत्युर्गन्धर्वस्तस्य विश्वमप्सरसो भुवो नाम स इदं ब्रह्मक्षत्रं पातु ता इदं ब्रह्मक्षत्रं पान्तु तस्मै स्वाहा ताभ्यः स्वाहा, सुक्षितिः सुभूतिर्भद्रकृत्सुवर्वान्पर्जन्यो गन्धर्वस्तस्य विद्युतोऽप्सरसो रुचो नाम स इदं ब्रह्मक्षत्रं पातु ता इदं ब्रह्मक्षत्रं पान्तु तस्मै स्वाहा ताभ्यः स्वाहा, दूरे हेति रमृडयो मृत्युर्गन्धर्वस्तस्य प्रजा अप्सरसो भीरुवो नाम स इदं ब्रह्मक्षत्रं पातु ता इदं ब्रह्मक्षत्रं पान्तु तस्मै स्वाहा ताभ्यः स्वाहा, चारुः कृपणकाशी कामो गन्धर्वस्त- स्याधयोऽप्सरसः शोचयन्तीर्नाम स इदं ब्रह्मक्षत्रं पातु ता इदं ब्रह्मक्षत्रं पान्तु तस्मै स्वाहा ताभ्यः स्वाहा, सनो भुवनस्य पते यस्य त उपरि गृहा इह च। उरुब्रह्मणेऽस्मै क्षत्राय महि शर्म यच्छ स्वाहा ॥९॥

नमो अस्तु सर्पेभ्यो ये के च पृथिवीमनु। ये अन्तरिक्षे ये दिवि तेभ्यः सर्पेभ्यो नमः॥ येऽदो रोचने दिवो ये वा सूर्यस्य रश्मिषु। येषामप्सु सदः कृतं तेभ्यः सर्पेभ्यो नमः॥ या इषवो यातुधानानां ये वा वनस्पतीꣳरनु। ये वाऽवटेषु शेरते तेभ्यः सर्पेभ्यो नमः॥१०॥

अयं पुरो हरिकेशः सूर्यरश्मिस्तस्य रथगृत्सश्चरथौजाश्च सेनानि ग्रामण्यौ पुंजिकस्थला च कृतस्थला चाप्सरसौ यातुधाना हेती रक्षाꣳसि प्रहेतिस्तेभ्यो नमस्ते नो मृडयन्तु ते यं द्विष्मो यश्च नो द्वेष्टि तं वो जंभे दधाम्ययं दक्षिणा विश्वकर्मा तस्य रथस्वनश्च रथे चित्रश्च सेनानि ग्रामण्यौ मेनका च सह जन्याचाप्सरसौ दंक्ष्णवः पशवो हेतिः पौरुषे यो वधः प्रहेतिस्तेभ्यो नमस्ते नो मृडयन्तु ते यं द्विष्मो यश्च नो द्वेष्टि तं वो जम्भे दधाम्ययं पश्चा- द्विश्वव्यचास्तस्य रथप्रोतश्चा समरथश्च सेनानि ग्रामण्यौ प्रम्लोचन्ती-

In Public domain. Digitization Muthulakshmi Research Academy

चानुम्लोचन्तीचाप्सरसौ सर्पा हेतिर्व्याघ्राः प्रहेतिस्तेभ्यो नमस्ते नो मृडयन्तु ते यं द्विष्मो यश्च नो द्वेष्टि तं वो जम्भे दधाऽम्ययमुत्तरात्संयद्वसुस्तस्य सेनजिच्च सुषेणश्च सेनानि ग्रामण्यौ विश्वाचीच घृताचीचाप्सरसावापो हेतिर्वातः प्रहेतिस्तेभ्यो नमस्तेनो मृडयन्तु ते यं द्विष्मो यश्च नो द्वेष्टि तं वो जम्भे दधाम्य-यमुपर्यर्वाग्वसुस्तस्य ताक्ष्यश्चारिष्टनेमिश्च सेनानि ग्रामण्यावुर्वशी च पूर्वचित्तिश्चाप्सरसौ विद्युद्धेतिरवस्फूर्जन्प्रहेतिस्तेभ्यो नमस्ते नो मृडयन्तु ते यं द्विष्मो यश्च नो द्वेष्टि तं वो जम्भे दधामि ॥११॥

आशुः शिशानो वृषभो न युध्मोघनाघनः क्षोभण-श्चर्षणी-नाम्। संक्रन्दनोऽनिमिष एकवीरः शतꣳसेना अजय-त्साकमिन्द्रः। संक्रन्दनेनानिमिषेण जिष्णुनायुत्कारेण दुश्च्यवनेन धृष्णुना। तदिन्द्रेण जयत तत्सहध्वं युधो नर इषु हस्तेन वृष्णा। स इषु हस्तैस्सनिषंगिभिर्वशीस ꣳस्त्रष्टा स युध इन्द्रो गणेन। सꣳसृष्ट-जित्सोमपा बाहुशध्यूर्ध्वधन्वा प्रतिहिताभिर स्ता। बृहस्पते परि दीया रथेन रक्षोहाऽमित्राꣳ अप बाधमानः। प्रभंजन् सेनाः प्रमृणो युधा जयन्नस्माकमेद्ध्य वितारथानाम्। गोत्रभिदं गोविदं बज्रबाहुं जयन्तमज्म प्रमृणन्तमोजसा। इमꣳ सजाता अनुवीर यध्वमिन्द्रꣳ सखायोऽनुसꣳरभध्वम्। बलविज्ञाय स्स्थविरः प्रवीरस्सहस्वान् वाजी सहमान उग्रः। अभि वीरो अभि सत्वासहो जाजैत्रमिन्द्र-रथमातिष्ठगोवित्। अभिगोत्राणि सहसागाह मानोऽदायो वीरश्शतमन्युरिन्द्रः। दुश्च्यवनः पृतनाषाडयुद्ध्योऽस्माकꣳ सेना अवतु प्रयुथ्सु। इन्द्र आसान्नेता बृहस्पतिर्दक्षिणा यज्ञः पुर एतु सोमः। देवसेनानामभिभंजतीनां जयन्तीनां मरुतो यन्त्वग्रे। इन्द्रस्य वृष्णो वरुणस्य राज्ञ आदित्यानां मरुताꣳशर्द्ध उग्रम्। महामनसां भुवनच्यवानां घोषो देवानां जयतामुदस्थात्।

In Public domain. Digitization Muthulakshmi Research Academy

अस्माकमिन्द्रस्समृतेषु ध्वजेष्वस्माकं या इषवस्ता जयन्तु। अस्माकं वीरा उत्तरे भवन्त्वस्मानु देवा अवता हवेषु। उद्धर्षय मघवन्नायुधा न्युत्सत्वनां मामकानां महाꣳसि। उद्वृत्रहन् वाजिनां वाजिनान्युद्रथानां जयतामेतु घोषः। उप प्रेत जयता नरः स्थिरा वस्सन्तु बाहवः। इन्द्रो वश्शर्म यच्छत्वनाधृष्यायथाऽसथ। अवसृष्टा परा पत शरव्ये ब्रह्मस-ꣳशिता। गच्छामित्रान् प्र विशमैषां कंचनोच्छिषः। मर्माणि ते वर्मभिश्छादयामि सोमस्त्वा राजाऽमृतेनाभि वस्ताम्। उरोर्वरीयो वरिवस्ते अस्तु जयन्तं त्वामनुमदन्तु देवाः। यत्र बाणाः संपतन्ति कुमारा विशिखा इव। इन्द्रो नस्तत्र वृत्रहा विश्वाहा शर्म यच्छतु॥१२॥

शंच मे मयश्च मे प्रियं च मेऽनु कामश्च मे कामश्च मे सौमनसश्च मे भद्रं च मे श्रेयश्च मे वस्यश्च मे यशश्च मे भगश्च मे द्रविणं च मे यन्ता च मे धर्ता च मे क्षेमश्च मे धृतिश्च मे विश्वं च मे महश्च मे संविच्च मे ज्ञात्रं च मे सूश्च मे प्रसूश्च मे सीरं च मे लयश्च मऋतं च मेऽमृतं च मेऽयक्ष्मं च मेऽनामयच्च मे जीवातुश्च मे दीर्घायुत्वं च मेऽनमित्रं च मेऽभयं च मे सुगं च मे शयनं च मे सूषा च मे सुदिनं च मे॥१३॥

ममाग्ने वर्चो विहवेष्वस्तु वयं त्वेन्धानास्तनुवं पुषेम। मह्यं नमन्तां प्रदिशश्चतस्त्रस्त्वयाध्यक्षेण पृतना जयेम। मम देवा विहवे सन्तु सर्व इन्द्रावन्तो मरुतो विष्णुरग्निः। ममान्तरिक्षमुरुगोपमस्तु मह्यं वातः पवतां कामे अस्मिन्। मयि देवा द्रविणमायजन्तां मय्याशीरस्तु मयि देवहूतिः। दैव्या होतारा वनिषन्त पूर्वेऽरिष्टा-स्स्यामतनुवा सुवीराः। मह्यं यजन्तु मम यानि हव्याऽऽकूतिः सत्या मनसो मे अस्तु॥ एनो मानिगां कतमच्चनाहं विश्वे देवासो अधिवोच ता मे। देवीष्षडुर्वीरुरुणः कृणोत विश्वे देवा स इह

In Public domain. Digitization Muthulakshmi Research Academy

वीरयध्वम्। माहास्महि प्रजया मा तनूभिर्मारधामद्विषते सोम-
राजन्। अग्निर्मन्युं प्रतिनुदन् पुरस्ताऽददब्धो गोपाः परिपाहि
नस्त्वम्। प्रत्यंचो यन्तु निगुतः पुनस्तेऽमैषा चित्तं प्रबुधा विनैशत्।
धाता धातृणां भुवनस्य यस्पतिर्देवꣳ सवितारमभिमातिषाहम्। इमं
यज्ञमश्विनोभा बृहस्पतिर्देवाः पान्तु यजमानन्न्यर्थात्। उरुव्यचानो
महिषश्शर्म यꣳ सदस्मिन् हवे पुरुहूतः पुरुक्षु। स नः प्रजायै हर्यश्व
मृडयेन्द्र मा नो रीरिषो मापरादाः। येनस्सपत्ना अप ते भवन्त्वि-
न्द्राग्निभ्यामवबाधामहेतान्। वसवो रुद्रा आदित्या उपरिस्पृशं
मोग्रं चेत्तारमधिराजमक्रन्न्। अर्वांचमिन्द्रममुतो हवामहे यो गोजि-
द्धनजिद श्वजिद्यः। इमं नो यज्ञं विहवे जुषस्वास्य कुर्मो हरिवो
मेदिनं त्वा॥१४॥

अग्नेर्मन्वे प्रथमस्य प्रचेतसोयं पांचजन्यं बहवस्समिन्धते।
विश्वस्यां विशि प्रविविशिवाꣳ समीमहे स नो मुंचत्वꣳ हंसः।
यस्येदं प्राणन्निमिषद्यदेजति यस्य जातं जनमानं च केवलम्।
स्तौम्यग्निं नाथितो जोहवीमि सनो मुंचत्वꣳहंसः। इन्द्रस्य मन्ये
प्रथमस्य प्रचेतसो वृत्रघ्नः स्तोमा उप मामुपागुः। योदाशुषः सुकृतो
हवमुपगन्ता सनोमुंचत्वꣳ हंसः। यः संग्रामं नयति संवशी युधेयः
पुष्टानि सꣳसृजति त्रयाणि। स्तौमीन्द्रं नाथितो जोहवीमि स नो
मुंचत्वꣳ हंसः। मन्वेवां मित्रा वरुणा तस्य वित्तꣳ सत्यो जसा दृꣳ
हणा यन्नुदेथे। या राजानꣳ सरथं याथ उग्राता नो मुंचत मागसः।
यो वाꣳरथ ऋजुरश्मिः सत्यधर्मा मिथुश्चरन्तमुपयाति दूषयन्न्।
स्तौमि मित्रावरुणा नाथितो जोहवीमि तौ नो मुंचतमागसः।
वायोस्सवितुर्विदथानि मन्महे यावात्म न्वद् बिभृतो यौ च रक्षतः।
यौ विश्वस्य परिभू बभूवतुस्तौ नो मुंचतमागसः। उपश्रेष्ठा न
आशिषो देवयोर्धर्मे अस्थिरन्न्। स्तौमि वायुꣳ सवितारं नाथितो

In Public domain. Digitization Muthulakshmi Research Academy

जोहवीमि तौ नौ मुंचत मार्गसः। रथी तमौ रथीनामह्व ऊतये शुभंगमिष्ठौ सुयमैभिरश्वैः। ययो र्वान्देवौ देवेष्वनिशि तमोजस्तौ नौ मुंचत मार्गसः। यदयातं वहतुं सूर्यायास्त्रिचक्रेण सꣳसदमिच्छमानौ। स्तौमि देवावश्विनौ नाथितो जोहवीमि तौ नौ मुंचत मार्गसः। मरुतां मन्वे अधिनो ब्रुवन्तु प्रेमां वाचं विश्वामवन्तु विश्वे। आशून् हुवेसुयमा नूतये ते नौ मुंचन्त्वे नसः। तिग्ममायुधं वीडितꣳसहस्वद्दिव्यꣳशर्द्धः पृतनासु जिष्णु। स्तौमि देवान्मरुतो नाथितो जोहवीमि ते नौ मुंचन्त्वेनसः। देवानां मन्वे अधि नो ब्रुवन्तु प्रेमां वाचं विश्वामवन्तु विश्वे। आशून् हुवे सुयमानूतये ते नौ मुंचन्त्वेनसः। यदिदं मा ऽभिशोचति पौरुषेयेण दैव्येन। स्तौमि विश्वान् देवान्नाथितो जोहवीमि ते नौ मुंचन्त्वेनसः। अनुनोऽद्यानुमतिर्यज्ञं देवेषु मन्यताम्। अग्निश्च हव्यवाहनो भवतांदाशुषे मयः॥ अन्विदनुमते त्वं मन्यासैशंच नः कृधि। क्रत्वे दक्षाय नो हि नु प्रण आयूꣳषि तारिषः॥ वैश्वानरो न ऊत्याऽऽप्रयातु परावतः। अग्निरुक्थेन वाहसा॥ पृष्टो दिवि पृष्टो अग्निः पृथिव्यां पृष्टो विश्वा ओषधीराविवेश। वैश्वानरस्सहसा पृष्टो अग्निस्सनो दिवा सरिषः पातु नक्तम्। ये अप्रथेताममि-तेभिरोजोभिर्येप्रतिष्ठे अभवतां वसूनाम्। स्तौमि द्यावापृथिवी नाथितो जोहवीमि ते नौ मुंचतमꣳहसः। उर्वी रोदसी वरिवः कृणोतं क्षेत्रस्य पत्नी अधि नो ब्रूयातम्। स्तौमि द्यावापृथिवी नाथितो जोहवीमि ते नौ मुंचतमꣳहसः। यत्ते वयं पुरुषत्रायविष्ठा विद्वाꣳ सश्च कृमा कच्चनागः। कृधी स्वस्माꣳ अदितेर नागा व्येनाꣳसि शिश्रथो विष्वगग्ने। यथा ह तद्वसवो गौर्यं चित्पदि षितामसुंचतायजत्राः। एवा त्वमस्मत्प्रमुञ्चाव्यꣳहः प्रातार्यग्ने प्रतरां न आयुः॥१५॥

In Public domain. Digitization Muthulakshmi Research Academy

समीची नामासि प्राचीदिक् तस्यास्तेऽग्निरधिपतिरसि तो रक्षिता यश्चाधिपतिर्यश्च गोप्ता ताभ्यां नमस्तौ नौ मृडयतां ते यं द्विष्मो यश्च नो द्वेष्टि तं वां जंभे दधाम्योजस्विनीनामासि दक्षिणा-दिक् तस्यास्त इन्द्रोऽधिपतिः पृदाकूरक्षिता यश्चाधिपतिर्यश्च गोप्ता ताभ्यां नमस्तौ नौ मृडयतां ते यं द्विष्मो यश्च नो द्वेष्टि तं वां जंभे दधामि प्राचीनामासि प्रतीचीदिक् तस्यास्ते सोमो ऽधिपतिस्स्वजो रक्षिता यश्चाधिपतिर्यश्च गोप्ता ताभ्यां नमस्तौ नौ मृडयतां ते यं द्विष्मो यश्च नो द्वेष्टि तं वां जंभे दधाम्यवस्था वा नामास्युदीची दिक् तस्यास्ते वरुणोऽधिपतिस्तिरश्च राजीरक्षिता यश्चाधिपतिर्यश्च गोप्ता ताभ्यां नमस्तौ नौ मृडयतां ते यं द्विष्मो यश्च नो द्वेष्टि तं वां जंभे दधाम्यधिपत्नी नामासि बृहती दिक् तस्यास्ते बृहस्पतिर-धिपतिः श्वित्रो रक्षिता यश्चाधिपतिर्यश्च गोप्ता ताभ्यान्नमस्तौ नौ मृडयतां ते यं द्विष्मो यश्च नो द्वेष्टि तं वां जंभे दधामि वशिनी नामासीयं दिक् तस्यास्ते यमोऽधिपतिः कल्माषग्रीवो रक्षिता यश्चाधिपतिर्यश्च गोप्ता ताभ्यां नमस्तौ नौ मृडयतां ते यं द्विष्मो यश्च नो द्वेष्टि तं वां जंभे दधामि॥१६॥

हेतयो नामस्थ तेषाँ वः पुरो गृहा अग्निर्व इषवः सलिलो वातनामं तेभ्यौ वो नमस्ते नौ मृडयत ते यं द्विष्मो यश्च नो द्वेष्टि तं वो जंभे दधामि, निलिम्पा नामस्थ तेषाँ वो दक्षिणा गृहाः पितरो व इषवोस्सगरो वातनामं तेभ्यौ वो नमस्ते नौ मृडयत ते यं द्विष्मो यश्च नो द्वेष्टि तं वो जंभे दधामि, वज्रिणो नामस्थ तेषाँ वः पश्चाद्गृहाः स्वप्नो व इषवो गह्वरो वात नामं तेभ्यौ वो नमस्ते नौ मृडयत ते यं द्विष्मो यश्च नोद्वेष्टि तं वो जंभे दुधाम्यवस्था वा नो नामस्थ तेषाँ व उत्तराद् गृहा आपो व इषवः समुद्रो वा त नामं तेभ्यौ वो नमस्ते नौ मृडयत ते यं द्विष्मो यश्च नोद्वेष्टि तं वो जंभे दधाम्यधिपतयो नामस्थ

In Public domain. Digitization Muthulakshmi Research Academy

तेषाँ व उपरि गृहा वर्षं व इषवोऽवस्वान् वातनामं तेभ्यौं वो नमस्ते नौ मृडयत ते यं द्विष्मो यश्च नो द्वेष्टि तं वो जंभै दधामि, क्रव्या नामस्थ पार्थिवास्तेषाँ व इहगृहा अन्नं व इषवो निमिषो वातनामं तेभ्यौं वो नमस्तेनौ मृडयत ते यं द्विष्मो यश्च नो द्वेष्टि तं वो जंभै दधामि ॥१७॥

शतायुधाय शतवी॑र्याय शतोतये ऽभिमातिषाहे॑। शतं यो नः शरदो अजीतानिन्द्रो नेषदति दुरितानि विश्वा॑। ये चत्वारः पथयौ देवयाना अन्तरा द्यावा पृथिवी वियन्ति। तेषां यो अज्यानि-मजीति मावहात् तस्मै॑ नो देवाः परिदत्तेहसर्वे॑। ग्रीष्मो हेमन्त उत नौ वसन्तः शरद्वर्षाः सुवितन्नौ अस्तु। तेषा मृतूना ँ शत शारदानान्निवात एषामभये स्याम। इदुवत्सराय परिवत्सराय संवत्सराय कृणुता बृहन्नमः। तेषाँ वय ँ सुमतौ यज्ञियानां ज्यो-गजीता अहताः स्याम। भद्रान्नः श्रेयस्समं नैष्टदेवास्त्वया ऽवसेन समशीमहित्वा। सनौ मयो भूः पितो आविशस्व शन्तोकाय तनुवे॑ स्यो नः ॥१८॥

भूतं भव्यं॑ भविष्यद्वषट् स्वाहा नम ऋक् साम यजु वषट् स्वाहा नमौ गायत्री त्रिष्टुब् जगती वषट् स्वाहा नमः पृथिव्यन्तरिक्षं द्यौ वषट् स्वाहा नमो ऽग्निर्वायुस्सूर्यो वषट्स्वाहा नमः प्राणो व्यानोऽपानो वषट्स्वाहा नमोऽन्नं कृषिर्वृष्टिर्वषट्स्वाहा नमः पिता-पुत्रः पौत्रो वषट् स्वाहानमो भूर्भुवस्सुवर्वषट् स्वाहा नमः ॥१९॥

इन्द्रो दधीचो अस्थभिः। वृत्राण्यप्रतिष्कुतः। जघान नवतीर्नव। इच्छन्नश्वस्य यच्छिरः। पर्वतेष्वपश्रितम्। तद्विदच्छर्य-णावति। अत्राहगोरमन्वत। नाम त्वष्टुरपीच्यम्। इत्थाचन्द्रमसो गृहे। इन्द्र मिद्गाथिनो बृहत्। इन्द्र मर्केभिरर्किणः। इन्द्रं वाणीर-

In Public domain. Digitization Muthulakshmi Research Academy

नूषत। इन्द्र इद्धर्योस्सचा। संमिश्ल आवचोयुजा। इन्द्रो वज्री हिरण्ययः। इन्द्रो दीर्घाय चक्षसे। आसूर्यं रोहयद्दिवि। विगोभि रद्रिमैरयत्। इन्द्रवाजेषु नो अव। सहस्र प्रधनेषु च। उग्र उग्राभि-रूतिभिः। तमिन्द्रं वाजया मसि। महे वृत्राय हन्तवे। सवृषा वृषभो भुवत्। इन्द्रस्सदा मने कृतः। ओजिष्ठस्सबलै हितः। द्युम्नी श्लोकी ससौम्यः। गिरा वज्रो न संभृतः। सबलो अनपच्युतः। ववक्षुरुग्रो अस्तृतः॥२०॥

चक्षुषो हेते मनसो हेते। वाचो हेते ब्रह्मणो हेते। योमा ऽघायुरभिदासति। तमग्ने मेन्याऽमेनिं कृणु। यो मा चक्षुषा यो मनसा। यो वाचा ब्रह्मणाऽघायुरभिदासति। तयाऽग्ने त्वं मेन्या। अमुममेनिं कृणु। यत्किंचासौ मनसा यच्च वाचा। यज्ञैर्जुहोति यजुषा हविर्भिः। तन्मृत्युर्निरृत्या संविदानः। पुरादिष्टादाहुतीरस्य हन्तु। यातुधाना निरृति रादुरक्षः। ते अस्यघ्नन्त्वनृतेन सत्यम्। इन्द्रेषिता आज्यमस्य मथ्नन्तु। मा तत्समृद्धि यदसौ करोति। हन्मि तेऽहंकृतं हविः। यो मे घोर-मची कृतः। अपाचौ त उभौ बाहू। अपनह्याम्यास्यम्। अपनह्यामि ते बाहू। अपनह्याम्यास्यम्। अग्नेर्देवस्य ब्रह्मणा। सर्वं तेऽवधिषंकृतम्। पुराऽमुष्य वषट्-कारात्। यज्ञं देवेषु नस्कृधि। स्विष्टमस्माकं भूयात्। माऽस्मान् प्रापन्नरातयः। अन्तिदूरे सतो अग्ने। भ्रातृव्यस्याभिदासतः। वषट्कारेण वज्रेण॥ कृत्यांहन्मि कृतामहम्। यो मा नक्तं दिवा सायम्। प्रातश्चाह्नो निपीयति। अद्यातमिन्द्र वज्रेण। भ्रातृव्यं पादयामसि॥२१॥

प्राणो रक्षति विश्वमेजत्। इर्यो भूत्वा बहुधा बहूनि। स इत्सर्वं व्यानशे। यो देवो देवेषु विभूरन्तः। आवृदूदात् क्षेत्रिय-ध्वगद्वृषा। तमित्प्राणं मनसोपशिक्षत। अग्रं देवा नामिदमंत्तु नो

In Public domain. Digitization Muthulakshmi Research Academy

हविः। मनस्सश्चित्तेदम्। भूतं भव्यं च गुप्यते। तद्धिदेवेष्वग्रियम्। आन एतु पुरश्चशम्। सहदेवैरिम ँ हवम्। मनः श्रेयसि श्रेयसि। कर्मन् यज्ञपतिं दधत्। जुषतां मे वागिद ँ हविः। विराड्देवी पुरोहिता। हव्यवाडनपायिनी। यया रूपाणि बहुधा वदन्ति। पेशा ँसि देवाः परमे जनित्रे। सा नो विराडनपस्फुरन्ती। वाग्देवी जुषतामिद ँ हविः। चक्षुर्देवानां ज्योतिरमृतेन्यक्तम्। अस्य विज्ञानाय बहुधानिधीयते। तस्य सुम्नमशीमहि। मा नो हासी द्विचक्षणम्। आयुरिन्नः प्रतीर्यताम्। अनन्धाश्चक्षुषा वयम्। जीवा ज्योतिरशीमहि। सुवज्योंतिरुतामृतम्। श्रोत्रेण भद्रमुत श्रृण्वन्ति सत्यम्। श्रोत्रेण वाचं बहुधो द्यमानाम्॥ श्रोत्रेण मोदश्च महश्च श्रूयते। श्रोत्रेण सर्वा दिश आश्रृणोमि। येन प्राच्या उत दक्षिणा। प्रतीच्यै दिशः श्रृण्वन्त्युत्तरात्। तदिच्छ्रोत्रं बहुधोद्यमानम्। अरान्ननेमिः परिसर्वं वभूव॥२२॥

सि ँहे व्याघ्र उत या पृदाकौ। त्विषिरग्नौ ब्राह्मणे सूर्येया। इन्द्रं यादेवी सुभगा जजान। सा न आगन्वर्चसा संविदाना। याराजन्ये दुन्दुभावायताायाम्। अश्वस्य क्रन्द्ये पुरुषस्य मायौ। इन्द्रं या देवी सुभगा जजान। सा न आगन्वर्चसा संविदाना। या हस्तिनि द्वीपिनि या हिरण्ये। त्विषिरश्वेषु पुरुषेषु गोषु। इन्द्रं या देवी सुभगा जजान। सा न आगन्वर्चसा संविदाना। रथे अक्षेषु वृषभस्य वाजे। वाते पर्जन्ये वरुणस्य शुष्मे। इन्द्रं या देवी सुभगा जजान। सा न आगन्वर्चसा संविदाना। राडसि विराडसि। सम्राडसि स्वराडसि। इन्द्राय त्वा तेजस्वते तेजस्वन्त ँ श्रीणामि। इन्द्राय त्वौजस्वत ओजस्वन्त ँ श्रीणामि। इन्द्राय त्वा पयस्वते पयस्वन्त ँ श्रीणामि। इन्द्राय त्वाऽऽयुष्मत आयुष्मन्त ँ श्रीणामि। तेजोऽसि। तत्ते प्रयच्छामि। तेजस्वदस्तु मे मुखम्।

In Public domain. Digitization Muthulakshmi Research Academy

तेजस्वच्छिरो अस्तु मे। तेजस्वान् विश्वतः प्रत्यङ्। तेजसा संपिपृग्धिमा। ओजोसि। तत्ते प्रयच्छामि। ओजस्वदस्तु मे मुखम्। ओजस्वच्छिरो अस्तु मे। ओजस्वान् विश्वतः प्रत्यङ्। ओजसा संपिपृग्धि मा। पयोऽसि। तत्ते प्रयच्छामि। पयस्वदस्तु मे मुखम्। पयस्वच्छिरो अस्तु मे। पयस्वान् विश्ववतः प्रत्यङ्। पयसा संपिपृग्धि मा। आयुरसि। तत्ते प्रयच्छामि। आयुष्मदस्तु मे मुखम्। आयुष्मच्छिरो अस्तु मे। आयुष्मान् विश्वतः प्रत्यङ्। आयुषा संपिपृग्धिमा। इममग्न आयुषे वर्चसे कृधि। प्रियꣳरेतो वरुण सोम राजन्। मा ते वास्मा अदिते शर्म यच्छ। विश्वे देवा जरदष्टिर्यथाऽसत्। आयुरसि विश्वायुरसि। सर्वायुरसि सर्वमायुरसि। यतो वातो मनो जवाः। यतः क्षरन्ति सिन्धवः। तासां त्वा सर्वासाꣳरुचा। अभिषिंचामि वर्चसा। समुद्र इवासि गह्मना। सोम इवास्यदाभ्यः। अग्निरिव विश्वतः प्रत्यङ्। सूर्य इव ज्योतिषा विभूः। अपां यो द्रवणे रसः। तमहमस्मा आमुष्यायणाय। तेजसे ब्रह्मवर्चसाय गृह्णामि। अपां य ऊर्मौरसः। तमहमस्मा आमुष्यायणाय। ओजसे वीर्याय गृह्णामि। अपां यो मध्यतो रसः। तमहमस्मा आमुष्यायणाय। पुष्ट्यै प्रजननाय गृह्णामि। अपां यो यज्ञियो रसः। तमहमस्मा आमुष्यायणाय। आयुषे दीर्घायुत्वाय गृह्णामि॥२३॥

अहमस्मि प्रथमजा ऋतस्य। पूर्वं देवेभ्यो अमृतस्य नाभिः। यो मा ददाति स इदेव मा वाः। अहमन्नमन्नमदन्तमद्मि। पूर्वमग्नेरपि दहत्यन्नम्। यत्तौ हासाते अहमुत्तरेषु। व्यात्तमस्य पशवस्सुजम्भम्। पश्यन्ति धीराः प्रचरन्ति पाकाः। जहाम्यन्यन्नजहाम्यन्यम्। अहमन्नं वशमिच्चरामि। समानमर्थं पर्येमि भुञ्जत्। को मामन्नं मनुष्यो दयेत। पराके अन्नं निहितं लोक एतत्।

In Public domain. Digitization Muthulakshmi Research Academy

विश्वैर्देवैः पितृभिर्गुप्तमन्नम्। यद्द्यते लुप्यते यत्परोप्यते। शतत-
मीसा तनूर्मे बभूव। महान्तौ चरू सकृद्दुग्धेन पप्रौ। दिवं च पृश्नि
पृथिवीं च साकम्। तत्संपिबन्तो नमिनन्ति वेधसः। नैतद्भूयो
भवति नो कनीयः। अन्नं प्राणमन्नमपानमाहुः। अन्नं मृत्युं तमु
जीवातु माहुः। अन्नं ब्रह्माणो जरसं वदन्ति। अन्नमाहुः प्रजननं
प्रजानाम्। मोघमन्नं विन्दते अप्रचेताः। सत्यं ब्रवीमि वध
इत्सतस्य। नार्यमणं पुष्यति नो सखायम्। केवलाघो भवति
केवलादी। अहं मेघः स्तनयन् वर्षन्नस्मि। मामदन्त्यह-मद्म्य-
न्यान्॥ अहꣳसदमृतो भवामि। मदादित्या अधिसर्वे तपन्ति।
देवीं वाचमजनयन्त देवाः। तां विश्वरूपाः पशवो वदन्ति। सा नो
मन्द्रेषमूर्जं दुहाना। धेनुर्वागस्मानुपसुष्टुतैतु। यद्वाग्वदन्त्य-
विचेतनानि। राष्ट्री देवानान्निषसादमन्द्रा। चतस्र ऊर्जं दुदुहे
पयाꣳसि। क्वस्विदस्याः परमं जगाम॥ अनन्ता-मन्तादधि
निर्मितां महीम्। यस्यां देवा अदधुर्भोजनानि। एका-क्षरान्
द्विपदाꣳ षट्पदांच। वाचं देवा उपजीवन्ति विश्वे। वाचं देवा
उपजीवन्ति विश्वे। वाचं गन्धर्वाः पशवो मनुष्याः। वाचीमा-
विश्वा भुवनान्यर्पिता। सा नो हवं जुषतामिन्द्रपत्नी। वागक्षरं
प्रथमजा ऋतस्य। वेदानां माताऽमृतस्य नाभिः। सानो जुषाणोप
यज्ञमागात्। अवन्ती देवी सुहवा मे अस्तु। यामृषयो मन्त्रकृतो
मनीषिणः। अन्वैच्छन्देवास्तपसा श्रमेण। तां देवीं वाचꣳहविषा
यजामहे। सा नो दधातु सुकृतस्य लोके। चत्वारि वाक् परिमिता
पदानि। तानि विदुर्ब्राह्मणा ये मनीषिणः। गुहा त्रीणि निहिता
नेंगयन्ति। तुरीयं वाचो मनुष्या वदन्ति। श्रद्धयाऽग्निः
समिध्यते। श्रद्धया विन्दते हविः। श्रद्धां भगस्य मूर्धनि। वचसा
वेदयामसि। प्रियꣳश्रद्धेददतः। प्रियꣳ श्रद्धे दिदासतः। प्रियं

In Public domain. Digitization Muthulakshmi Research Academy

भोजेषु यज्वसु। इदं मं उदितं कृधि। यथा देवा असुरेषु। श्रद्धा-मुग्रेषु चक्रिरे। एवं भोजेषु यज्वसु। अस्माकमुदितं कृधि। श्रद्धां देवा यजमानाः। वायुगोपा उपासते। श्रद्धाꣳहृदय्ययाऽऽकूत्या। श्रद्धया हूयते हविः। श्रद्धां प्रातर्हवामहे। श्रद्धां मध्यंदिनं परि। श्रद्धाꣳ सूर्यस्य निम्रुचि। श्रद्धे श्रद्धापयेह माँ। श्रद्धा देवानधिवस्ते। श्रद्धा विश्वमिदं जगत्। श्रद्धां कामस्य मातरम्। हविषा वर्धयामसि। ब्रह्मजज्ञानं प्रथमं पुरस्तात्। विसीमतस्सुरुचो वेन आवः। स बुध्नियां उपमा अस्य विष्ठाः। सतश्च योनिमसतश्च विवः। पिता विराजामृषभो रयीणाम्। अन्तरिक्षं विश्वरूप आविवेश। तमर्कैरभ्यर्चन्ति वत्सम्। ब्रह्म सन्तं ब्रह्मणा वर्द्धयन्तः। ब्रह्म देवानजनयत्। ब्रह्म विश्वमिदं जगत्। ब्रह्मणः क्षत्रन्निर्मितम्। ब्रह्म ब्राह्मण आत्मनाँ। अन्तरस्मिन्निमे लोकाः। अन्तर्विश्वमिदं जगत्। ब्रह्मैव भूताना ञ्ज्येष्ठम्। तेन कोऽर्हति स्पर्द्धितुम्। ब्रह्मन्देवास्त्रयस्त्रिꣳशत्। ब्रह्मन्निन्द्रप्रजापती। ब्रह्मन् ह विश्वा भूतानि। नावीवान्तः समाहिता। चतस्र आशाः प्रचरन्त्वग्नयः। इमं नो यज्ञं नयतु प्रजानन्न्। घृतं पिन्वन्नजरꣳसुवीरम्। ब्रह्मसमिद्भवत्याहुतीनाम्। आगावो अग्मन्नुत भद्रमक्रन्न्। सीदन्तु गोष्ठे रणयन्त्वस्मे। प्रजावतीः पुरुरूपा इह स्युः। इन्द्राय पूर्वीरुषसो दुहानाः। इन्द्रो यज्वने पृणते च शिक्षति। उपेद्ददाति न स्वं मुषायति। भूयो भूयो रयिमिदस्य वर्द्धयन्न्। अभिन्ने खिल्ले निदधाति देवयुम्। न ता नशन्ति न दभाति तस्करः। नैना अमित्रो व्यथिरादधर्षति। देवाꣳश्च याभिर्यजते ददाति च। ज्योगित्ताभिस्सचते गोपतिः सह। न ता अर्वा रेणुककाटो अश्नुते। न सꣳस्कृतत्र मुपयन्ति ता अभि। उरुगायमभयन्तस्य ता अनु। गावो मर्त्यस्य विचरन्ति यज्वनः।

In Public domain. Digitization Muthulakshmi Research Academy

गावो भगो गाव इन्द्रो मे अच्छात्। गावः सोमस्य प्रथमस्य भक्षः॥ इमा यागावस्सजना स इन्द्रः। इच्छामीद्धृदा मनसा चिदिन्द्रम्। यूयं गावो मेदयथा कृशंचित्। अश्लीलं चित्कृणुथा सुप्रतीकम्। भद्रं गृहं कृणुथ भद्रवाचः। बृहद्वो वय उच्यते सभासु। प्रजावतीः सूयवसꣳरिशन्तीः। शुद्धा अपस्सु प्रपाणे पिबन्तीः। मावस्तेन ईशत माघशꣳसः। परि वोहेती रुद्रस्य वृंज्यात्। उपेदमुपपर्चनम्। आसु गोषूप पृच्यताम्। उपर्षभस्य रेतसि। उपेन्द्र तव वीर्ये॥२४॥

ता सूर्या चन्द्रमसा विश्वभृत्तमामहत्। तेजो वसु मद्राजतो दिवि। सामात्मानाचरतस्साम चारिणा। ययोर्व्रतन्नममे जातु- देवयोः। उभावन्तौ परियात अम्र्या। दिवो नरश्मीꣳस्तनुतो- व्यर्णवे। उभा भुवन्ती भुवना कविक्रतू। सूर्या न चन्द्रा चरतो हतामती। पती द्युमद्विश्वविदा उभा दिवः। सूर्या उभा चन्द्रमसा विचक्षणा। विश्ववारा वरि वो भावरेण्या। ता नोऽवतं मतिमन्ता महिव्रता। विश्व वपरी प्रतरणा तरन्ता। सुवर्विदा दृशये भूरि रश्मी। सूर्या हि चन्द्रा वसुत्वेष दर्शता। मनस्विनो भाऽनुचरतो- नुसंदिवम्। अस्य श्रवो नद्यः सप्त बिभ्रति। द्यावा क्षामा पृथिवी दर्शतं वपुः। अस्मे सूर्या चन्द्रमसाऽभिचक्षे। श्रद्धेकमिन्द्र चरतो विर्चतुरम्। पूर्वापरं चरतो माययैतौ। शिशूक्रीडन्तौ परियातो अध्वरम्। विश्वान्यन्यो भुवनाऽभिचष्टे। ऋतूनन्यो विदधज्जायते पुनः। हिरण्यवर्णाः शुचयः पावका यासु जातः कश्यपो यास्विन्द्रः। अग्निं या गर्भं दधिरे विरूपास्ता न आपः शꣳ स्योना भवन्तु। यासाꣳराजा वरुणो याति मध्ये सत्यानृते अवपश्यञ्जनानाम्। मधुश्चुतश्शुचयो याः पावकास्ता न आपः शꣳ स्योना भवन्तु। यासां देवादिवि कृण्वन्ति भक्षं या अन्तरिक्षे

In Public domain. Digitization Muthulakshmi Research Academy

बहुधा भवन्ति। याः पृथिवीं पयसोन्दन्ति शुक्रास्ता न आपः शꣳ स्योना भवन्तु। शिवेन मा चक्षुषा पश्यतापः शिवया तनुवोपस्पृशत त्वचं मे। सर्वाꣳ अग्नीꣳ रप्सुषदो हुवे वो मयि वर्चो बलमोजो निधत्त। आपो भद्रा घृतमिदाप आसुरग्नीषोमौ बिभ्रत्याप इत्ताः। तीव्रो रसो मधुपृचामरंगम आ मा प्राणेन सह वर्चसागन्। आदित्पश्याम्युत वा शृणोम्यामा घोषो गच्छति वाङ् न आसाम्। मन्ये भेजानो अमृतस्य तर्हि हिरण्यवर्णा अतृपं यदावः। नासदासीन्नोसदासीत्तदानीम्। नासीद्रजो नोव्यो मापरोयत्। किमावरीवः कुह कस्य शर्मन्न्। अम्भः किमासीद्गहनं गभीरम्। न मृत्युरमृतं तर्हि न। रात्रिया अह्न आसीत् प्रकेतः। आनी दवातꣳ स्वधया तदेकम्। तस्माद्धान्यं न परः किंचनास। तम आसीत्तमसा गूढमग्रे प्रकेतम्। सलिलꣳ सर्वं मा इदम्। तुच्छेनाभ्वपिहितं यदासीत्। तमसस्तन्महिना जायतैकम्। कामस्तदग्रे समवर्तताधि। मनसो रेतः प्रथमं यदासीत्। स तो बन्धुमसति निरविन्दन्। हृदिप्रतीष्या कवयो मनीषा। तिरश्चीनो विततो रश्मिरेषाम्। अधस्विदासी (३) दुपरि स्विदासी (३) त्। रेतोधा आसन्महिमा न आसन्। स्वधा अवस्तात् प्रयतिः परस्तात्। को अद्धा वेद क इह प्रवोचत्। कुत आ जाता कुत इयं विसृष्टिः। अर्वाग्देवा अस्य विसर्जनाय। अथा को वेदयत आ बभूव। इयं विसृष्टिर्यत आबभूव। यदिवादधे यदिवा न। यो अस्याध्यक्षः परमे व्योमन्न्। सो अंग वेद यदि वा न वेद। किꣳ स्विद्वनं क उ स वृक्ष आसीत्। यतो द्यावा पृथिवी निष्टतक्षुः। मनीषिणो मनसापृच्छतेदु तत्। यदध्यतिष्ठद् भुवनानि धारयन्न्। ब्रह्मवनं ब्रह्म सवृक्ष आसीत्। यतो द्यावापृथिवी निष्टतक्षुः। मनीषिणो मनसा विब्रवीमि वः। ब्रह्माध्यतिष्ठद् भुवनानि धारयन्न्। प्रातरग्निं

In Public domain. Digitization Muthulakshmi Research Academy

प्रातरिन्द्रꣳ हवामहे। प्रातर्मित्रावरुणा प्रातरश्विना। प्रातर्भगं पूषणं ब्रह्मणस्पतिम्। प्रातस्सोममुत रुद्रꣳ हुवेम। प्रातर्जितं भगमुग्रꣳ हुवेम। वयं पुत्रमदितेर्यो विधर्ता। आद्ध्रश्चिद्यं मन्यमानस्तुरश्चित्। राजा चिद्यं भगं भक्षीत्याह। भगप्रणेतर्भग सत्यराधः। भगेमान्धियमुदवददन्नः। भगप्रणो जनयगोभिरश्वैः। भग प्रनृभिर्नृवन्तः स्याम। उतेदानीं भगवन्तः स्याम। उत प्रपित्व उत मध्ये अह्नाम्। उतोदिता मघवन् सूर्यस्य। वयं देवानाꣳसुमतौ स्याम। भग एव भगवाꣳअस्तु देवाः। तेन वयं भगवन्तः स्याम। तन्त्वा भग सर्व इज्जोहवीमि। स नो भग पुर एता भवेह। समध्वरायोषसो नमन्त। दधिक्रावेव शुचये पदाय। अर्वाचीनं वसुविदं भगन्नः। रथमिवाश्वा वाजिन आवहन्तु। अश्वावतीर्गोमतीर्न उषासः। वीरवतीः सदमुच्छन्तु भद्राः। घृतं दुहाना विश्वतः प्रपीनाः। यूयं पात स्वस्तिभिः सदा नः॥२५॥

अग्निर्नः पातु कृत्तिकाः। नक्षत्रं देवमिन्द्रियम्। इदमासां विचक्षणम्। हविरासंजुहोतन। यस्य भान्ति रश्मयो यस्य केतवः। यस्येमा विश्वा भुवनानि सर्वा। स कृत्तिकाभिरभिसंवसानः। अग्निर्नो देवः सुविते दधातु॥ प्रजापते रोहिणी वेतु पत्नी॥ विश्वरूपा बृहती चित्रभानुः। सा नो यज्ञस्य सुविते दधातु। यथा जीवेम शरदस्सवीराः। रोहिणीदेव्युदगात्पुरस्तात्। विश्वा रूपाणि प्रतिमोदमाना। प्रजापतिꣳ हविषा वर्द्धयन्ती। प्रिया देवाना मुपयातु यज्ञम्॥ सोमो राजा मृगशीर्षेण आगन्न्। शिवं नक्षत्रं प्रियमस्य धाम। आप्यायमानो बहुधा जनेषु। रेतः प्रजां यजमाने दधातु। यत्ते नक्षत्रं मृगशीर्षमस्ति। प्रियꣳराजन् प्रियतमं प्रियाणाम्। तस्मै ते सोम हविषा विधेम। शन्न एधि द्विपदे शं चतुष्पदे॥ आर्द्रया रुद्रः प्रथमा न एति। श्रेष्ठो देवानां

In Public domain. Digitization Muthulakshmi Research Academy

पतिं रघ्नियानाम्। नक्षत्रमस्य हविषा विधेम। मा नः प्रजाꣳरीरिषन्मोतवीरान्। हेती रुद्रस्य परिणो वृणक्तु। आर्द्रा नक्षत्रं जुषताꣳहविर्नः। प्रमुंचमानौ दुरितानि विश्वा। अपाघशꣳसन्नुदतामरातिम्॥ पुनर्नोदेव्यदितिः स्पृणोतु। पुनर्वसूनः पुनरेता यज्ञम्। पुनर्नो देवा अभियन्तु सर्वे। पुनः पुनर्वो हविषा यजामः। एवान देव्यदितिरनर्वा। विश्वस्य भर्त्री जगतः प्रतिष्ठा। पुनर्वसू हविषा वर्द्धयन्ती। प्रियं देवानामप्यैतु पाथः॥ बृहस्पतिः प्रथमं जायमानः। तिष्यंनक्षत्रमभिसंबभूव। श्रेष्ठो देवानां पृतनासु जिष्णुः। दिशोनु सर्वा अभयन्नो अस्तु। तिष्यः पुरस्तादुत मध्यतो नः। बृहस्पतिर्नः परिपातु पश्चात्। बाधेतान्द्वेषो अभयं कृणुताम्। सुवीर्यस्य पतयः स्याम॥ इदꣳ-सर्पेभ्यो हविरस्तु जुष्टम्। आ श्रेषा येषामनुयन्ति चेतः। ये अन्तरिक्षं पृथिवीं क्षियन्ति। ते नस्सर्पासो हवमागमिष्ठाः॥ ये रोचने सूर्यस्यापि सर्पाः। ये दिवं देवीमनुसंचरन्ति। येषामाश्रेषा अनुयन्ति कामम्। तेभ्यः सर्पेभ्यो मधुमज्जुहोमि॥ उपहूताः पितरो ये मघासु। मनोजवसः सुकृतः सुकृत्याः। ते नो नक्षत्रे हवमागमिष्ठाः। स्वधाभिर्यज्ञं प्रयतं जुषन्ताम्। ये अग्निदग्धा येऽनग्निदग्धाः। येऽमुंल्लोकं पितरः क्षियन्ति। याꣳश्च विद्मयाꣳउ च न प्रविद्म। मघासु यज्ञꣳ सुकृतं जुषन्ताम्॥ गवां पतिः फल्गुनीनामसि त्वम्। तदर्यमन्वरुणमित्र चारु। तं त्वा वयꣳ सनितारꣳ सनीनाम्। जीवा जीवन्तमुपसंविशेम। येनेमा विश्वा भुवनानि संजिता। यस्य देवा अनुसंयन्ति चेतः। अर्यमा राजाऽजरस्तु विष्मान्। फल्गुनीनामृषभो रोरवीति॥ श्रेष्ठो देवानां भगवो भगासि। तं त्त्वा विदुः फल्गुनीस्तस्य वित्तात्। अस्मभ्यं क्षत्रमजरꣳ सुवीर्यम्। गोमदश्ववदुपसन्नुदेह। भगो ह दाता भग इत् प्रदाता। भगो देवीः

In Public domain. Digitization Muthulakshmi Research Academy

फल्गुनीराविवेश। भगस्येत्तं प्रसवं गमेम। यत्र देवैः सधमादं मदेम॥ आयातु देवस्सवितोपयातु। हिरण्ययेन सुवृता रथेन। वहन् हस्तꣳसुभगं विद्मनापसम्। प्रयच्छन्तं पपुरिं पुण्यमच्छ। हस्तः प्रयच्छ त्वमृतं वसीयः। दक्षिणेन प्रतिगृभ्णीम एनत्। दातार-मद्य सविता विदेय। यो नो हस्ताय प्रसुवाति यज्ञम्॥ त्वष्टा नक्षत्रमभ्येति चित्राम्। सुभꣳससंयुवतिꣳरोचमानाम्। निवेशयन्नमृतान्मर्त्याꣳश्च। रूपाणि पिꣳशन् भुवनानि विश्वा। तन्नस्त्वष्टा तदु चित्रा विचष्टाम्। तन्नक्षत्रं भूरिदा अस्तु मह्यम्। तन्नः प्रजां वीरवतीꣳ सनोतु। गोभिर्नो अश्वैः समनक्तु यज्ञम्॥ वायुर्नक्षत्रमभ्यैति निष्ट्याम्। तिग्मश्रृंगो वृषभो रोरुवाणः। समीरयन् भुवना मातरिश्वा। अपद्वेषाꣳसि नुदतामरातीः। तन्नो वायुस्तदुनिष्ट्या शृणोतु। तन्नक्षत्रं भुरिदा अस्तु मह्यम्। तन्नो देवासो अनुजानन्तु कामम्। यथातरेम दुरितानि विश्वा॥ दूरमस्मच्छत्रवो यन्तु भीताः। तदिन्द्राग्नी कृणुतां तद्विशाखे। तन्नो देवा अनुमदन्तु यज्ञम्। पश्चात्पुरस्तादभयन्नो अस्तु। नक्षत्राणामधिपत्नी विशाखे। श्रेष्ठाविन्द्राग्नी भुवनस्य गोपौ। विषूचश्शत्रूनप- वाधमानौ। अपक्षुधन्नुद तामरातिम्॥ पूर्णापश्चादुत पूर्णा पुरस्तात्। उन्मध्यतः पौर्णमासी जिगाय। तस्यां देवा अधिसंवसन्तः। उत्तमे नाक इह मादयन्ताम्। पृथ्वी सुवर्चा युवतिस्सजोषाः। पौर्णमास्युदगाच्छोभमाना। आप्याय-यन्ती दुरितानि विश्वा। उरुन्दुहां यजमानाय यज्ञम्॥ २६ ॥

ऋद्ध्यास्म हव्यैर्नमसोपसद्य। मित्रं देवं मित्रधेयं नो अस्तु। अनूराधान् हविषा वर्धयन्तः। शतं जीवेम शरदः सवीराः। चित्रं नक्षत्रमुदगात्पुरस्तात्। अनूराधा स इति यद्वदन्ति। तन्मित्र एति पथिभिर्देवयानैः। हिरण्ययैर्विततैरन्तरिक्षे॥ इन्द्रो ज्येष्ठामनु-

In Public domain. Digitization Muthulakshmi Research Academy

नक्षत्रमेति। यस्मिन्वृत्रं वृत्रतूर्ये ततार। तस्मिन्वयममृतं दुहानाः। क्षुधन्तरे मदुरितिन्दुरिष्टिम्। पुरन्दराय वृषभाय धृष्णवे। अषाढाय सहमानाय मीढुषे। इन्द्राय ज्येष्ठा मधुमद्दुहाना। उरुंकृणोतु यजमानाय लोकम्॥ मूलं प्रजां वीरवतीं विदेय। पराच्येतु निरृतिः पराचा। गोभिर्नक्षत्रं पशुभिस्समक्तम्। अहर्भूयाद्यजमानाय मह्यम्॥ अहर्नो अद्य सुविते दधातु। मूलं नक्षत्रमिति यद्वदन्ति। पराचीं वाचा निरृतिं नुदामि। शिवं प्रजायै शिवमस्तु मह्यम्॥ या दिव्या आपः पयसा संबभूवुः। या अन्तरिक्ष उत पार्थिवीर्याः। यासामषाढा अनुयन्ति कामम्। ता न आपश्शꣳ स्योना भवन्तु। याश्च कूप्या याश्च नाद्यास्समुद्रियाः। याश्च वैशन्तीरुत प्रासचीर्याः। यासामषाढा मधु भक्षयन्ति। ता न आपश्शꣳस्योना भवन्तु॥ तन्नो विश्वे उपशृण्वन्तु देवाः। तदषाढा अभि संयन्तु यज्ञम्। तन्नक्षत्रं प्रथतां पशुभ्यः। कृषिर्वृष्टिर्यजमानाय कल्पताम्। शुभ्राः कन्या युवतयस्सुपेशसः। कर्मकृतः सुकृतो वीर्यावतीः। विश्वान् देवान् हविषा वर्धयन्तीः। अषाढाः काममुपयान्तु यज्ञम्॥ यस्मिन् ब्रह्माभ्यजयत् सर्वमेतत्। अमुं चलोकमिदमूच सर्वम्। तन्नो नक्षत्रमभिजिद्विजित्य। श्रियं दधात्वहृणीयमानम्। उभौ लोकौ ब्रह्मणा संजितेमौ। तन्नो नक्षत्रमभिजिद्विचष्टाम्। तस्मिन् वयं पृतनास्संजयेम। तन्नो देवासो अनुजानन्तु कामम्। शृण्वन्ति श्रोणाममृतस्य गोपाम्। पुण्यामस्या उप शृणोमि वाचम्। महीं देवीं विष्णुपत्नीमजूर्याम्। प्रतीचीमेनाꣳ हविषा यजामः॥ त्रेधा विष्णुरुरुगायो विचक्रमे। महीं दिवं पृथिवी मन्तरिक्षम्। तच्छ्रोणैति श्रव इच्छमाना। पुण्यꣳश्लोकं यजमानाय कृण्वती॥ अष्टौ देवा वसवः सोम्यासः। चतस्रो देवीरजराः श्रविष्ठाः। ते यज्ञं पान्तु रजसः परस्तात्। संवत्सरीणममृतꣳ स्वस्ति। यज्ञं नः पान्तु

In Public domain. Digitization Muthulakshmi Research Academy

वसवः पुरस्तात्। दक्षिणतोऽभियन्तु श्रविष्ठाः। पुण्यन्नक्षत्र-
मभिसंविशाम। मा नो अरातिरघशꣳ सागन्॥ क्षत्रस्य राजा
वरुणोऽधिराजः। नक्षत्राणाꣳ शतभिषग्वसिष्ठः। तौ देवेभ्यः
कृणुतो दीर्घमायुः। शतꣳ सहस्रा भेषजानिधत्तः। यज्ञं नो राजा
वरुण उपयातु। तन्नो विश्वे अभिसंयन्तु देवाः। तन्नो नक्षत्रꣳ
शतभिषग्जुषाणम्। दीर्घमायुः प्रतिरद्भेषजानि॥ अज एकपादु-
दगात्पुरस्तात्। विश्वा भूतानि प्रतिमोदमानः। तस्य देवाः प्रसवं
यन्ति सर्वे। प्रोष्ठपदासो अमृतस्य गोपाः। विभ्राजमानः समिधान
उग्रः। आऽन्तरिक्ष मरुहदगन्द्याम्। तꣳसूर्यं देवमज-मेकपादम्।
प्रोष्ठपदासो अनुयन्ति सर्वे॥ अहिर्बुध्नियः प्रथमा न एति। श्रेष्ठो
देवाना मुत मानुषाणाम्। तं ब्राह्मणाः सोमपाः सोम्यासः।
प्रोष्ठपदासो अभिरक्षन्ति सर्वे। चत्वार एकमभिकर्म देवाः।
प्रोष्ठपदास इति यान् वदन्ति। ते बुध्नियं परिषद्यꣳ स्तुवन्तः।
अहिꣳरक्षन्ति नमसोपसद्य॥ पूषा रेवत्यन्वेति पन्थाम्। पुष्टिपती
पशुपावाजबस्त्यौ। इमानि हव्या प्रयता जुषाणा। सुगैर्नो
यानैरुपयातां यज्ञम्। क्षुद्रान् पशून् रक्षतु रेवती नः। गावो नो
अश्वाꣳ अन्वेतु पूषा। अन्नꣳरक्षन्तौ बहुधा विरूपम्।
वाजꣳसनुतां यजमानाय यज्ञम्॥ तदश्विनावश्वयुजो-पयाताम्।
शुभं गमिष्ठौ सुयमेभिरश्वैः। स्वन्नक्षत्रꣳ हविषा यजन्तौ।
मध्वासंपृक्तौ यजुषा समक्तौ। यौ देवाना भिषजौ हव्यवाहौ।
विश्वस्य दूतावमृतस्य गोपौ। तौ नक्षत्रं जुजुषाणोपयाताम्।
नमोऽश्विभ्यां कृणुमोऽश्वयुग्भ्याम्॥ अप पाप्मानं भरणी भरन्तु।
तद्यमो राजा भगवान् विचष्टाम्। लोकस्य राजा महतो महान् हि।
सुगन्नः पन्थामभयं कृणोतु। यस्मिन्नक्षत्रे यम एति राजा।
यस्मिन्नेनमभ्यषिंचन्त देवाः। तदस्य चित्रꣳ हविषा यजाम। अप

In Public domain. Digitization Muthulakshmi Research Academy

पाप्मानं भरणीर्भरन्तु॥ निवेशनी संगमनी वसूनां विश्वा रूपाणि वसून्यावेशयन्ती। सहस्त्रपोषꣳ सुभगा रराणा सा न आगन् वर्चसा संविदाना। यत्ते देवा अदधुर्भागधेयममावास्ये संवसन्तो महित्वा॥ सा नो यज्ञं पिपृहि विश्ववारे रयिन्नो धेहि सुभगे सुवीरम्॥२७॥

नवो नवो भवति जायमानोऽह्नां केतुरुषसामेत्यग्रे। भागं देवेभ्यो विदधात्यायन् प्रचन्द्रमास्तिरति दीर्घमायुः॥ यमादित्या अꣳशुमाप्याय यन्ति यमक्षितमक्षितयः पिबन्ति। तेन नो राजा वरुणो बृहस्पतिराप्यायं यन्तु भुवनस्य गोपाः॥ (चन्द्रमसे स्वाहा प्रती दृश्यायै स्वाहा। अहोरात्रेभ्यः स्वाहा ऽर्धमासेभ्य स्वाहा। मासेभ्यः स्वाहर्तुभ्यः स्वाहा। संवत्सराय स्वाहा॥)

ये विरूपे समनसा संव्ययन्ती। समानं तन्तुं परितातनाते। विभू प्रभू अनुभू विश्वतो हुवे। ते नो नक्षत्रे हवमागमेतम्। वयं देवी ब्रह्मणा संविदानाः। सुरत्नासो देववीतिं दधानाः। अहोरात्रे हविषा वर्धयन्तः। अति पाप्मानमतिमुक्त्या गमेम॥ (अह्ने स्वाहा रात्रियै स्वाहा। अतिमुक्त्यै स्वाहा॥)

प्रत्युव दृश्यायती। व्युच्छन्ती दुहिता दिवः। अपो मही वृणुते चक्षुषा। तमो ज्योतिष्कृणोतिसूनरी। उदु स्त्रियास्सचते सूर्यः। स चा उद्यन्नक्षत्रमर्चिमत्। तवेदुषो व्युषि सूर्यस्य च। संभक्तेन गमेमहि॥ (उषसेस्वाहा व्युष्टयै स्वाहा। व्यूषुष्यै स्वाहा व्युच्छन्त्यै स्वाहा। व्युष्टायै स्वाहा॥)

तन्नो नक्षत्रमर्चिमत्। भानुमत्तेज उच्चरत्। उपयज्ञमिहागमत्। प्रनक्षत्रायदेवाय। इन्द्रायेन्दुꣳ हवामहे। स नः सविता सुवत्सनिम्। पुष्टिदां वीरवत्तमम्॥ (नक्षत्राय स्वाहो देष्यते स्वाहा। उद्यते स्वाहोदिताय स्वाहा। हरसे स्वाहा भरसे स्वाहा।

In Public domain. Digitization Muthulakshmi Research Academy

भ्राजसे स्वाहा तेजसे स्वाहा। तपसे स्वाहा ब्रह्मवर्चसाय स्वाहा॥)

उदुत्यं जातवेदसं देवं वहन्ति केतवः। दृशे विश्वाय सूर्यम्। चित्रं देवानामुदगादनीकं चक्षुर्मित्रस्य वरुणस्याग्नेः। आऽप्राद्यावा पृथिवी अन्तरिक्षꣳसूर्य आत्मा जगतस्तस्थुषश्च॥ (सूर्याय स्वाहा नक्षत्रेभ्यः स्वाहा। प्रतिष्ठायै स्वाहा॥)

अदितिर्न उरुष्यत्वदितिः शर्म यच्छतु। अदितिः पात्वꣳहसः। महीमूषु मातरꣳ सुव्रतानामृतस्य पत्नीमवसे हुवेम। तुविक्षत्रामजरन्तीमुरूचीꣳ सुशर्माणमदितिꣳ सुप्रणीतिम्॥ (अदित्यै स्वाहा प्रतिष्ठायै स्वाहा॥)

इदं विष्णुर्विचक्रमे त्रेधा निदधे पदम्। समूढमस्यपाꣳसुरे। प्रतद्विष्णुः स्तवते वीर्याय। मृगो न भीमः कुचरो गिरिष्ठाः। यस्योरुषु त्रिषु विक्रमणेषु। अधिक्षियन्ति भुवनानि विश्वा॥ (विष्णवे स्वाहा यज्ञाय स्वाहा। प्रतिष्ठायै स्वाहा॥)

अग्निर्मूर्धा दिवः ककुत्पतिः पृथिव्या अयम्। अपाꣳरेताꣳसि जिन्वति। भुवो यज्ञस्य रजसश्च नेता यत्रानियुद्भिः स च से शिवाभिः। दिवि मूर्धानं दधिषे सुवर्षा जिह्वा मग्ने चकृषे हव्यवाहम्॥ (अग्नये स्वाहा॥)

अनुनोऽद्यानु मतिर्यज्ञं देवेषु मन्यताम्। अग्निश्च हव्यवाहनो भवतां दाशुषे मयः। अन्विदनुमते त्वं मन्यासै शंच नः कृधि। क्रत्वे दक्षाय नोहि नु प्रण आयूꣳषि तारिषः॥ (अनुमत्यै स्वाहा॥)

हव्यवाहमभिमातिषाहम्। रक्षोहणं पृतनासु जिष्णुम्। ज्योतिष्मन्तं दीद्यतं पुरन्धिम्। अग्निꣳ स्विष्टकृत माहुवेम। स्विष्टमग्ने अभितत् पृणाहि। विश्वा देव पृतना अभिष्य। उरुन्नः पन्था प्रदिशन् विभाहि। ज्योतिष्मद्धेह्यजरन्न आयुः॥२८॥ (अग्नये स्विष्ट कृते स्वाहा॥)

In Public domain. Digitization Muthulakshmi Research Academy

अग्नये स्वाहा कृत्तिकाभ्यः स्वाहा। अम्बायै स्वाहा दुलायै स्वाहा। नितत्यै स्वाहाऽभ्रयन्त्यै स्वाहा। मेघयन्त्यै स्वाहा वर्षयन्त्यै स्वाहा। चुपुणीकायै स्वाहा॥ प्रजापतये स्वाहा रोहिण्यै स्वाहा। रोचमानायै स्वाहा प्रजाभ्यः स्वाहा॥ सोमाय स्वाहा मृगशीर्षाय स्वाहा। इन्वकाभ्यः स्वाहौऽषधीभ्यः स्वाहा। राज्याय स्वाहाऽभिजित्यै स्वाहा॥ रुद्राय स्वाहाऽऽर्द्रायै स्वाहा। पिन्वमानायै स्वाहा पशुभ्यः स्वाहा॥ अदित्यै स्वाहा पुनर्वसुभ्याम्॥ स्वाहा भूत्यै स्वाहा प्रजात्यै स्वाहा॥ बृहस्पतये स्वाहा तिष्याय स्वाहा। ब्रह्मवर्चसाय स्वाहा॥ सर्पेभ्यः स्वाहाऽऽश्रेषाभ्यः स्वाहा। दन्दशूकेभ्यः स्वाहा॥ पितृभ्यः स्वाहा मघाभ्यः। स्वाहाऽनघाभ्यः स्वाहाऽगदाभ्यः॥ स्वाहाऽरुन्धतीभ्यः स्वाहा॥ अर्यम्णे स्वाहा फल्गुनीभ्याँ स्वाहा। पशुभ्यः स्वाहा॥ भगायस्वाहा फल्गुनीभ्याँ स्वाहा। श्रैष्ठ्याय स्वाहा॥ सवित्रेस्वाहा हस्ताय। स्वाहा ददतेस्वाहा पृणते। स्वाहा प्रयच्छते स्वाहा प्रतिगृभ्णते स्वाहा॥ त्वष्ट्रे स्वाहा चित्रायै स्वाहा। चैत्राय स्वाहा प्रजायै स्वाहा॥ वायवे स्वाहा निष्ट्यायै स्वाहा। कामचाराय स्वाहाऽभिजित्यै स्वाहा॥ इन्द्राग्निभ्याँस्वाहा विशाखाभ्याँ स्वाहा। श्रैष्ठ्याय स्वाहाऽभिजित्यै स्वाहा॥ पौर्णमास्यै स्वाहा कामाय स्वाहा गत्यै स्वाहा॥२९॥

मित्राय स्वाहाऽनूराधेभ्यः स्वाहा। मित्रधेयाय स्वाहाऽभिजित्यै स्वाहा॥ इन्द्रायस्वाहा ज्येष्ठायै स्वाहा। ज्यैष्ठ्याय स्वाहाऽभिजित्यै स्वाहा॥ प्रजापतये स्वाहा मूलायस्वाहा। प्रजायै स्वाहा॥ अद्भ्यः स्वाहाऽषाढाभ्यः स्वाहा। समुद्रायस्वाहा कामाय स्वाहा। अभिजित्यै स्वाहा॥ विश्वेभ्यो देवेभ्यः स्वाहाऽषाढाभ्यः स्वाहा। अनपजय्याय स्वाहा जित्यै स्वाहा॥ ब्रह्मणे

In Public domain. Digitization Muthulakshmi Research Academy

स्वाहाऽभिजिते स्वाहा। ब्रह्मलोकाय स्वाहाऽभिजित्यै स्वाहा॥ विष्णवे स्वाहा श्रोणायै स्वाहा। श्लोकाय स्वाहा श्रुतायस्वाहा॥ वसुभ्यः स्वाहा श्रविष्ठाभ्यः स्वाहा। अग्राय स्वाहा परीत्यैस्वाहा॥ वरुणायस्वाहा शतभिषजे स्वाहा। भेषजेभ्यः स्वाहा॥ अजायैकपदे स्वाहा प्रोष्ठपदेभ्यः स्वाहा। तेजसे स्वाहा ब्रह्मवर्चसाय स्वाहा॥ अहये बुध्नियाय स्वाहा प्रोष्ठपदेभ्यः स्वाहा। प्रतिष्ठायै स्वाहा॥ पूष्णे स्वाहा रेवत्यै स्वाहा। पशुभ्यः स्वाहा॥ अश्विभ्याꣳ स्वाहाऽश्वयुग्भ्याꣳ स्वाहा। श्रोत्राय स्वाहा श्रुत्यै स्वाहा॥ यमाय स्वाहाऽपभरणीभ्यः स्वाहा। राज्याय स्वाहाऽभिजित्यै स्वाहा॥ अमावास्यायै स्वाहा कामाय स्वाहा गत्यै स्वाहा॥३०॥

चन्द्रमसे स्वाहा प्रतीदृश्यायै स्वाहा। अहो रात्रेभ्यः स्वाहाऽर्द्धमासेभ्यः स्वाहा। मासेभ्यः स्वाहर्तुभ्य स्वाहा। संवत्सराय स्वाहा। अह्ने स्वाहा रात्रियै स्वाहा। अतिमुक्त्यै स्वाहा। उषसे स्वाहा व्युष्ट्यै स्वाहा। व्यूषुष्यै स्वाहा व्युच्छन्त्यै स्वाहा। व्युष्टायै स्वाहा। नक्षत्राय स्वाहोदेष्यते स्वाहा। उद्यते स्वाहोदितायस्वाहा। हरसे स्वाहा भरसे स्वाहा। भ्राजसे स्वाहा तेजसे स्वाहा। तपसे स्वाहा ब्रह्मवर्चसाय स्वाहा। सूर्याय स्वाहा नक्षत्रेभ्यः स्वाहा। प्रतिष्ठायै स्वाहा। अदित्यै स्वाहा प्रतिष्ठायै स्वाहा। विष्णवे स्वाहा यज्ञायस्वाहा। प्रतिष्ठायै स्वाहा॥३१॥

दधिक्राव्णो अकारिषं जिष्णोरश्वस्य वाजिनः। सुरभि नो मुखाकरत् प्रण आयूꣳषि तारिषत्। आपो हिष्ठा मयो भुवस्तान ऊर्जे दधातन। महे रणाय चक्षसे। यो वः शिवतमो रसस्तस्य भाजयतेह नः। उशतीरिव मातरः। तस्मा अरं गमाम वो यस्य क्षयाय जिन्वथ। आपो जनयथा च नः॥३२॥

In Public domain. Digitization Muthulakshmi Research Academy

उदुत्तमं वरुणपाशमस्मदवाधमं विमध्यमꣳ श्रथाय। अथा वयमादित्यव्रते तवानागसो अदितये स्याम। अस्तभ्नाद् द्यामृषभो अन्तरिक्षममिमीत वरिमाणं पृथिव्या आसीदद्विश्वा भुवनानि सम्राड्विश्वेत्तानि वरुणस्य व्रतानि। यत्किंचेदं वरुणदैव्ये जनेऽभिद्रोहं मनुष्याँश्चरामसि। अचित्तीयत्तव धर्मा युयोपिम मानस्तस्मादेनसो देव रीरिषः। कितवासो यद्रिरिपुर्न दीवि यद्वाघा सत्यमुतयन्न विद्म। सर्वा ता विष्य शिथिरेव देवाथा ते स्याम वरुणप्रियासः। अव ते हेडो वरुण नमोभिरवयज्ञेभिरीमहे हविर्भिः। क्षयन्नस्मभ्यमसुरप्रचेतो राजन्नेनाꣳसिशिश्रथः कृतानि। तत् त्वायामि ब्रह्मणा वन्दमानस्तदाशास्ते यजमानो हविर्भिः। अहेडमानो वरुणेहबोध्युरुशꣳस मा न आयुः प्रमोषीः॥३३॥

हिरण्यवर्णाः शुचयः पावका यासु जातः कश्यपो यास्विन्द्रः। अग्निं या गर्भं दधिरे विरूपास्तान आपः शꣳस्योना भवन्तु। यासाꣳ राजा वरुणो याति मध्ये सत्यानृते अवपश्यञ्जनानाम्। मधुश्चुतश्शुचयो याः पावकास्ता न आपः शꣳ स्योना भवन्तु। यासां देवा दिवि कृण्वन्ति भक्षं या अन्तरिक्षे बहुधा भवन्ति। याः पृथिवीं पयसोन्दन्ति शुक्रास्ता न आपः शꣳ स्योना भवन्तु। शिवेन मा चक्षुषा पश्यतापः शिवया तनुवोपस्पृशत त्वचं मे। सर्वाꣳ अग्नीꣳ रप्सुषदो हुवे वो मयि वर्चो बलमोजो निधत्त॥३४॥

पवमानः सुवर्जनः। पवित्रेण विचर्षणिः। यः पोता स पुनातु मा। पुनन्तु मा देवजनाः। पुनन्तु मनवो धिया। पुनन्तु विश्व आयवः। जातवेदः पवित्रवत्। पवित्रेण पुनाहि मा। शुक्रेण देव दीद्यत्। अग्ने क्रत्वा क्रतूꣳ रनु। यत्ते पवित्रमर्चिषि। अग्ने

In Public domain. Digitization Muthulakshmi Research Academy

विततमन्तरा। ब्रह्म तेन पुनीमहे। उभाभ्याँ देव सवितः। पवित्रेण सवेन च । इदं ब्रह्म पुनीमहे। वैश्वदेवी पुनती देव्यागात्। यस्यै बह्वीस्तनुवो वीतपृष्ठाः। तया मदन्तस्सधमाद्येषु। वयꣳ स्याम पतयो रयीणाम्। वैश्वानरो रश्मिभिर्मा पुनातु। वातः प्राणेनेषिरो मयो भूः। द्यावापृथिवी पयसा पयोभिः। ऋतावरी यज्ञिये मा पुनीताम्। बृहद्भिः सवितस्तृभिः। वर्षिष्ठैर्देवमन्मभिः। अग्ने दक्षैः पुनाहि मा। येन देवा अपुनत। येनापो दिव्यंकशः। तेन दिव्येन ब्रह्मणा। इदं ब्रह्म पुनीमहे। यः पावमानीरध्येति। ऋषिभिः संभृतꣳ रसम्। सर्वꣳ स पूतमश्नाति। स्वदितं मातरिश्वना। पावमानीर्यो अध्येति। ऋषिभिः संभृतꣳ रसम्। तस्मै सरस्वती दुहे। क्षीरꣳ सर्पिर्मधूदकम्। पावमानीः स्वस्त्ययनीः॥ सुदुघाहि पयस्वतीः। ऋषिभिः संभृतो रसः। ब्राह्मणेष्वमृतꣳ हितम्। पावमानीर्दिशन्तु नः। इमं लोकमथो अमुम्। कामान् समर्द्धयन्तु नः। देवी देवैः समाभृताः। पावमानीः स्वस्त्ययनीः। सुदुघाहि घृतश्चुतः। ऋषिभिः संभृतो रसः। ब्राह्मणेष्वमृतꣳ हितम्। येन देवाः पवित्रेण। आत्मानं पुनते सदा। तेन सहस्रधारेण। पावमान्यः पुनन्तु मा। प्राजापत्यं पवित्रम्। शतोद्यामꣳ हिरण्मयम्। तेन ब्रह्मविदो वयम्। पूतं ब्रह्म पुनीमहे। इन्द्रः सुनीती सह मा पुनातु। सोमः स्वस्त्या वरुणः समीच्या। यमो राजा प्रमृणाभिः पुनातु मा। जातवेदा मोर्जयन्त्या पुनातु॥३५॥

भूर्भुवस्सुवः। तच्छंयोरावृणीमहे। गातुं यज्ञाय। गातुं यज्ञपतये। दैवीः स्वस्तिरस्तु नः। स्वस्तिर्मानुषेभ्यः। ऊर्ध्वं जिगातु भेषजम्। शन्नो अस्तु द्विपदे। शं चतुष्पदे। ओं शान्तिः शान्तिः शान्तिः॥३६॥

In Public domain. Digitization Muthulakshmi Research Academy

नमो ब्रह्मणे नमो अस्त्वग्नये नमः पृथिव्यै नम ओषधीभ्यः। नमो वाचे नमो वाचस्पतये नमो विष्णवे बृहते करोमि॥ ओं शान्तिः शान्तिः शान्तिः॥३७॥

॥ उदकशान्ति-मन्त्रपाठः समाप्तः॥

॥ अभिषेक-द्रव्याणि ॥

प्रथमं गन्धतैलञ्च द्वितीयं पञ्चगव्यकम्।
पञ्चामृतं तृतीयं स्याद् घृतस्नानं चतुर्थकम्॥
पञ्चचमं पयसा स्नानं दधिस्नानं तु षष्ठकम्।
सप्तमं मधुनास्नान मिक्षुसारमथाष्टमम्॥
नवमं फलसारंस्याद् दशमं नालिकेरजम्।
एकादशं गन्धतोयं द्वादशं जलमुच्यते॥

॥ विभूति अभिषेक मन्त्राः ॥

This is recited during Abhishekam by Vibhuti after all Abhishekams to Siva)

१. प्राणापान व्यानोदान समाना मे शुद्ध्यन्तां ज्योतिरहं विरजा विपाप्मा भूयास ँ स्वाहा॥

२. वाङ्मनश्चक्षुश्श्रोत्र जिह्वा घ्राण रेतो बुद्ध्याकूति स्संकल्पा मे शुद्ध्यन्तां ज्योतिरहं विरजा विपाप्मा भूयास ँ स्वाहा॥

३. त्वक् चर्ममा ँ सरुधिर मेदो मज्जा स्नायवो ऽस्थीनि मे शुद्ध्यन्तां ज्योतिरहं विरजा विपाप्मा भूयास ँ स्वाहा॥

४. शिरः पाणि पाद पार्श्व पृष्ठो रुदर जंघ शिश्नोपस्थ पायवो मे शुद्ध्यन्तां ज्योतिरहं विरजा विपाप्मा भूयास ँ स्वाहा॥

५. उत्तिष्ठ पुरुष हरित पिङ्गळ लोहिताक्षि देहि देहि ददापयिता मे शुद्ध्यन्तां ज्योतिरहं विरजा विपाप्मा भूयास ँ

In Public domain. Digitization Muthulakshmi Research Academy

स्वाहा॥

६. पृथिव्याप स्तेजो वायु राकाशा मे शुद्ध्यन्तां ज्योतिरहं विरजा विपाप्मा भूयास ँ स्वाहा॥

७. शब्द स्पर्श रूप रस गन्धा मे शुद्ध्यन्तां ज्योतिरहं विरजा विपाप्मा भूयास ँ स्वाहा॥

८. मनोवाक्काय कर्माणि मे शुद्ध्यन्तां ज्योतिरहं विरजा विपाप्मा भूयास ँ स्वाहा॥

९. अव्यक्त भावै रहंकारै ज्योतिरहं विरजा विपाप्मा भूयास ँ स्वाहा॥

१०. आत्मा मे शुद्ध्यन्तां ज्योतिरहं विरजा विपाप्मा भूयास ँ स्वाहा॥

११. अन्तरात्मा मे शुद्ध्यन्तां ज्योतिरहं विरजा विपाप्मा भूयास ँ स्वाहा॥

१२. परमात्मा मे शुद्ध्यन्तां ज्योतिरहं विरजा विपाप्मा भूयास ँ स्वाहा॥

१३. क्षुधे स्वाहा। क्षुप्तिपासाय स्वाहा। विविट्यै स्वाहा। ऋग्विधानाय स्वाहा। कषोत्काय स्वाहा॥ क्षुप्तिपासा मलं ज्येष्ठा मलक्ष्मी नाँशया म्यहम्। अभूति मसं मृद्धिञ्च सर्वान् निर्णुद मे पाप्मान ँ स्वाहा॥

१४. अन्नमय प्राणमय मनोमय विज्ञानमय मानन्दमय मात्मा मे शुद्ध्यन्तां ज्योतिरहं विरजा विपाप्मा भूयास ँ स्वाहा॥

१५. ओं तद् ब्रह्म। ओं तद्वायुः। ओं तदात्मा। ओं तथ्सत्यम्। ओं तथ्सर्वम्। ओं तत् पुरोर्नमः। अन्तश्चरति भूतेषु गुहायां विश्वमूर्तिषु। त्वं यज्ञस्त्वं वषट्कारस्त्व मिन्द्रस्त्व ँ रुद्रस्त्वं विष्णुस्त्वं ब्रह्मत्वं प्रजापतिः। त्वं तदाप आपो

In Public domain. Digitization Muthulakshmi Research Academy

ज्योतीरसोऽमृतं ब्रह्म भू भुर्व स्सुवरोम्॥

१६. निधनपतये नमः। निधन पतान्तिकारा नमः॥ ऊर्ध्वाय नमः। ऊर्ध्व लिंगाय नमः॥ हिरण्याय नमः। हिरण्यलिंगाय नमः॥ सुर्वणाय नमः। सुवर्ण लिंगाय नः॥ दिव्याय नमः। दिव्य लिंगाय नमः॥ भवाय नमः। भवलिंगाय नमः॥ शर्वाय नमः। शर्व लिंगाय नमः॥ शिवाय नमः। शिवलिंगाय नमः॥ ज्वलाय नमः। ज्वल लिंगाय नमः॥ आत्माय नमः। आत्म लिंगाय नमः॥ परमाय नमः। परमलिंगाय नमः॥ एतथ्सोमस्य सूर्यस्य सर्वलिंगँ स्थापयति पाणिमन्त्रं पवित्रम्॥

॥ दक्षिणामूर्त्युपनिषत्॥

यस्मौनव्याख्यया मौनिपटलं क्षणमात्रतः।
महामौनपदं याति स हि मे परमा गतिः॥
ॐ सहनाववत्विति शान्तिः॥

ॐ ब्रह्मावर्ते महाभाण्डीरवटमूले महासत्राय समेता महर्षयः शौनकादयस्ते ह समित्पाणयस्तत्त्वजिज्ञासवो मार्कण्डेयं चिरंजीविनमुपसमेत्य पप्रच्छुः केन त्वं चिरं जीवसि केन वानन्द-मनुभवसीति। परमरहस्यशिवतत्त्वज्ञानेनेति स होवाच। किं तत्परमरहस्यशिवतत्त्वज्ञानम्। तत्र को देवः। के मन्त्राः। को जपः। का मुद्रा। का निष्ठा। किं तज्ज्ञानसाधनम्। कः परिकरः। को बलिः। कः कालः। किं तत्स्थानमिति। स होवाच। येन दक्षिणामुखः शिवोऽपरोक्षीकृतो भवति तत्परमरहस्यशिवतत्त्व-ज्ञानम्। यः सर्वोपरमे काले सर्वानात्मन्युपसंहृत्य स्वात्मानन्दसुखे मोदते प्रकाशते वा स देवः। अत्रैते मन्त्ररहस्यश्लोका भवन्ति। मेधा दक्षिणामूर्तिमन्त्रस्य ब्रह्मा ऋषिः। गायत्री छन्दः। देवता दक्षिणास्यः। मन्त्रेणाङ्गन्यासः। ॐ आदौ नम उच्चार्य ततो भगवते पदम्। दक्षिणेति पदं पश्चान्मूर्तये पदमुद्धरेत्॥१॥

In Public domain. Digitization Muthulakshmi Research Academy

अस्मच्छब्दं चतुर्थ्यन्तं मेधां प्रज्ञां पदं वदेत्। समुच्चार्य ततो वायु बीजं च्छं च ततः पठेत्। अग्निजायां ततस्त्वेष चतुर्विंशाक्षरो मनुः ॥२॥

ध्यानम्॥ स्फटिकरजतवर्णं मौक्तिकीमक्षमालाममृत-कलशविद्यां ज्ञानमुद्रां कराग्रे। दधमुरगकक्ष्यं चन्द्रचूडं त्रिनेत्रं विधृतविविधभूषं दक्षिणामूर्तिमीडे॥३॥

मन्त्रेण न्यासः। आदौ वेदादिमुच्चार्य स्वराद्यं सविसर्गकम्। पञ्चार्णं तत उद्धृत्य अन्तरं सविसर्गकम्। अन्ते समुद्धरेत्तारं मनुरेप नवाक्षरः॥४॥

मुद्रां भ्रदार्थदात्रीं स परशुहरिणं बाहुभिर्बाहुमेकं जान्वासक्तं दधानो भुजगबिलसमाबद्धकक्ष्यो वटाधः। आसीनश्चन्द्रखण्ड-प्रतिघटित जटाक्षीरगौरस्त्रिनेत्रो दद्यादाद्यः शुकाद्यैर्मुनिभिर-भिवृतो भावशुद्धिं भवो नः॥५॥

मन्त्रेण न्यासः ब्रह्मर्षिन्यासः—तारं ब्रूंनम उच्चार्य मायां वाग्भवमेव च। दक्षिणापदमुच्चार्य ततः स्यान्मूर्तये पदम्॥६॥

ज्ञानं देहि पदं पश्चाद्वह्निजायां ततो न्यसेत्। मनुरष्टा-दशार्णोऽयं सर्वमन्त्रोषु गोपितः॥७॥

भस्मव्यापाण्डुकराङ्गः शशिशकलधरो ज्ञानमुद्राक्षमाला-वीणापुस्तैर्विराजत्करकमलधरो[1] योगपट्टाभिरामः। व्याख्यापीठे निषण्णो मुनिवरनिकरैः सेव्यमानः[2] प्रसन्नः सव्यालः[3] कृत्तिवासाः सततमवतु नो दक्षिणामूर्तिरीशः॥८॥

मन्त्रेण न्यासः। (ब्रह्मर्षिन्यासः)। तारं[4] परं रमाबीजं[5] वदेतसाम्बशिवाय च। तुभ्यं चानलजायां च मनुर्द्वादश-वर्णकः॥९॥

वीणां करैः पुस्तकमक्षमालां बिभ्राणमभ्राणभगलं वराढ्यम्। फणीन्द्रकक्ष्यं मुनिभिः शुकाद्यैः सेव्यं वटाधः कृतनीडमीडे॥१०॥

विष्णु ऋषिरनुष्टुप्छन्दः। देवता दक्षिणास्यः। मन्त्रेण

१. करतलकमलो, २. सेवितः सुप्रसन्नः, ३. सव्याडः, ४. तारं मायां, ५. बीजं पदं

In Public domain. Digitization Muthulakshmi Research Academy

न्यासः। तारं नमो भगवते तुभ्यं वटपदं ततः। मूलेति पदमुच्चार्य वासिने पदमुद्धरेत्॥११॥

प्रज्ञामेधापदं पश्चादादिसिद्धिं ततो वदेत्। दायिने पदमुच्चार्य मायिने नम उद्धरेत्॥१२॥

वागीशाय ततः पश्चान्महाज्ञानपदं ततः। वह्निजायां ततस्त्वेष द्वात्रिंशद्वर्णको मनुः। आनुष्टुभो मन्त्रराजः सर्वमन्त्रोत्तमोत्तमः॥१३॥

ध्यानम्। मुद्रापुस्तकवह्निनागविलसद्बाहुं प्रसन्नाननं मुक्ताहारविभूषणं शशिकलाभास्वत्किरीटोज्ज्वलम्। अज्ञानापहमादिमादिमगिरामर्थं भवानीपतिं न्यग्रोधान्तनिवासिनं परगुरुं[1] ध्यायाम्यभीष्टाप्तये॥१४॥

मौनमुद्रा। सोऽहमिति यावदास्थितिः सनिष्ठा भवति। तदभेदेन मन्त्रामेडनं ज्ञानसाधनम्। चित्ते तदेकतानता परिकरः। अङ्गचेष्टार्पणं बलिः। त्रीणि धामानि कालः। द्वादशान्तपदं स्थानमिति। ते ह पुनः श्रद्दधानास्तं प्रत्यूचुः। कथं वाऽस्योदयः। किं स्वरूपम्। को वाऽस्योपासक इति। स होवाच। वैराग्यतैलसंपूर्णे भक्तिवर्तिसमन्विते। प्रबोधपूर्णपात्रे तु ज्ञप्तिदीपं विलोकयेत्॥१५॥

मोहान्धकारे निःसारे उदेति स्वयमेव हि। वैराग्यमरणिं कृत्वा ज्ञानं कृत्वा[2] तु चित्रगुम्।॥१६॥

गाढतामिस्रसंशान्त्यै गूढमर्थं निवेदयेत्। मोहभानुजसंक्रान्तं विवेकाख्यं मृकण्डुजम्॥१७॥

तत्त्वाविचारपाशेन बद्धं द्वैतभयातुरम्। उज्जीवयन्निजानन्दे स्वस्वरूपेण संस्थितः॥१८॥

शेमुषी दक्षिणा प्रोक्ता सा यस्यामीक्षणे मुखम्। दक्षिणाभिमुखः प्रोक्तः शिवोऽसौ ब्रह्मवादिभिः॥१९॥

सर्गादिकाले भगवान्विरिञ्चिरुपास्यैनं सर्गसामर्थ्यमाप्य। तुतोष चित्ते वाञ्छितार्थांश्च लब्ध्वा धन्यः सोपास्योपासको

१ सुरगुरं, २. कृत्वोत्तरारणिम्।

In Public domain. Digitization Muthulakshmi Research Academy

भवति धाता ॥२०॥

य इमां परमरहस्य शिवतत्त्वविद्यामधीते स सर्वपापेभ्यो मुक्तो भवति। य एवं वेद स कैवल्यमनुभवतीत्युपनिषत्॥ ॐ सहनाववत्विति शान्तिः॥ इति दक्षिणामूर्त्युपनिषत्समाप्ता॥

॥ श्री दक्षिणामूर्ति अष्टकम् ॥

१. मौनं व्याख्या प्रकटित परब्रह्म तत्वं युवानं
वर्षिष्ठान्ते वसद् ऋषि गणै रावृतं ब्रह्म निष्ठैः।
आचार्येन्द्रं करकलित चिन्मुद्र मानन्द मूर्तिं
स्वात्मा रामं मुदित वदनं दक्षिणामूर्ति मीड़े॥

२. विश्वं दर्पण दृश्यमान नगरी तुल्यं निजान्तर्गतं
पश्यन्नात्मनि मायया बहिरिवोद् भूतं यथा निद्रया।
यस्साक्षात् कुरुते प्रबोध समये स्वात्मान मेवाद्वयं
तस्मै श्री गुरुमूर्तये नम इदं श्री दक्षिणा मूर्तये॥

३. बीजस्यान्त रिवाङ्कुरो जगदिदं प्राङ् निर्विकल्पं पुनः
मायाकल्पित देशकाल कलना वैचित्र्य चित्रीकृतम्।
मायावीव विजृम्भयत्यपि महायोगीव यः स्वेच्छया
तस्मै श्री गुरुमूर्तये नम इदं श्री दक्षिणा मूर्तये॥

४. यस्यैव स्फुरणं सदात्मकमसत् कल्पार्थकं भासते
साक्षात् तत्व मसीति वेदवचसा यो बोधयत्याश्रितान्।
यत्साक्षात् करणाद् भवेन्न पुनरावृत्तिर्भवां भो निधौ
तस्मै श्री गुरुमूर्तये नम इदं श्री दक्षिणा मूर्तये॥

५. नानाच्छिद्र घटोदरस्थित महादीप प्रभा भास्वरं
ज्ञानं यस्यतु चक्षुरादि करण द्वारा बहिः स्पन्दते।
जानामीति तमेव भान्तं अनुभात्येतत् समस्तं जगत्
तस्मै श्री गुरु मूर्तये नम इदं श्री दक्षिणा मूर्तये॥

६. देहं प्राण मपीन्द्रियाण्यपि चलां बुद्धिं च शून्यं विदुः
स्त्री बालान्ध जडोपमास्त्वहमिति भ्रान्ता भृशंवादिनः।
मायाशक्ति विलास कल्पित महाव्यामोह संहारिणे
तस्मै श्री गुरुमूर्तये नम इदं श्री दक्षिणामूर्तये॥

In Public domain. Digitization Muthulakshmi Research Academy

७. राहुग्रस्त दिवाकरेन्दु सदृशो मायासमाच्छादनात्
सन्मात्रःकरणोप सहरणतो योऽभूत् सुषुप्तः पुमान्।
प्रागस्त्वाप्समिति प्रबोध समये यः प्रत्यभि ज्ञायते
तस्मै श्री गुरुमूर्तये नम इदं श्री दक्षिणामूर्तये॥

८. बाल्यादिष्वपि जाग्रदादिषु तथा सर्वास्व वस्था स्वपि
व्यावृत्तास्वनु वर्तमानमह मित्यन्तः स्फुरन्तं सदा।
स्वात्मानं प्रकटीकरोति भजतां यो मुद्रया भ्रदया
तस्मै श्री गुरुमूर्तये नम इदं श्री दक्षिणामूर्तये॥

९. विश्वं पश्यति कार्यकारणतया स्व स्वामि संबन्धतः
शिष्याचार्य तया तथैव पितृपुत्राद्यात्मना भेदतः।
स्वप्ने जाग्रति वा य एष पुरुषो माया परिभ्रामितः
तस्मै श्री गुरुमूर्तये नम इदं श्री दक्षिणामूर्तये॥

१०. भूरंभांस्यनलो ऽनिलोंबरमहर्नाथो हिमांशुः पुमान्
इत्याभाति चराचरात्मकमिदं यस्यैव मूर्त्यष्टकम्।
नान्यत् किञ्चन विद्यते विमृशतां यस्मात् परस्माद विभोः
तस्मै श्री गुरुमूर्तये नम इदं श्री दक्षिणामूर्तये॥

११. सर्वात्वमिति स्फुटीकृतमिदं यस्मा दमुष्मिन् स्तवे
तेनास्य श्रवणात् तदर्थ मननात् ध्यानाच्च संकीर्तनात्।
सर्वात्मत्व महाविभूति सहितं स्यादीश्वरत्वं स्वतः
सिद्धयेत् तत्पुनरष्टधा परिणतं चैश्वर्य मव्याहतम्॥

१२. वटविटपि समीपे भूमि-भागे निषण्णं
सकल मुनि जनानां ज्ञानदातार मारात्।
त्रिभुवन गुरुमीशं दक्षिणामूर्ति देवं
जनन मरण दुःख़च्छेद दक्षं नमामि॥

१३. चित्रं वटतरोर्मूले वृद्धाः शिष्या गुरुर्युवा।
गुरोस्तु मौनं व्याख़्यानं शिष्यास्तु छिन्न संशयाः॥

१४. ओं नमः प्रणवार्थाय शुद्धज्ञानैक मूर्तये।
निर्मलाय प्रशान्ताय दक्षिणामूर्तये नमः॥

In Public domain. Digitization Muthulakshmi Research Academy

१५. गुरुवे सर्वलोकानां भिषजे भवरोगिणाम्।
निधये सर्वविद्यानां श्री दक्षिणामूर्तये नमः ॥

१६. अंगुष्ठ तर्जनी योगमुद्रा व्याजेन देहिनाम्।
श्रुत्यर्थं ब्रह्म जीवैक्यं दर्शयन्नो ऽवताच्छिवः ॥

१७. नारायणं पद्मभुवं वसिष्ठं, शक्तिं च तत्पुत्र पराशरं च।
व्यासं शुकं गौडपदं महान्तं, गोविन्द योगीन्द्र मथास्य शिष्यम्॥
श्री शंकराचार्य मथास्य पद्मपादं च, हस्तामलकं च शिष्यम्।
तं तोटकं वार्तिक कारमन्यान्, अस्मद् गुरून् सन्तत मानतोस्मि॥

१८. सदाशिव समारंभां शंकराचार्य मध्यमाम्।
अस्मदाचार्य पर्यन्तां वन्दे गुरुपरंपराम्॥

॥ तोटकाष्टकम् ॥

१. विदिताखिल शास्त्र सुधा जलधे — महितोपनिषत् कतितार्थ निधे।
हृदये कलये विमलं चरणं — भव शंकर देशिक मे शरणम्॥

२. करुणावरुणालय पालय मां — भव सागर दुःख विदूनहृदम्।
रचयाखिल दर्शन तत्व विदं — भव शंकर देशिक मे शरणम्॥

३. भवता जनता सुहिता भविता — निज बोध विचारण चारुमते।
कलयेश्वर जीव विवेक विदं — भव शंकर देशिक मे शरणम्॥

४. भव एव भवानिति मे नितरां — समजायत चेतसि कौतुकिता।
मम वारय मोह महाजलधिं — भव शंकर देशिक मे शरणम्॥

५. सुकृतेऽधिकृते बहुधा भवतो — भविता समदर्शन लालसता।
अतिदीनमिमं परिपालयमां — भव शंकर देशिक मे शरणम्॥

६. जगतीमवितुं कलिता कृतयो — विचरन्ति महामह सश्चछलतः।
अहिमांशु रिवात्र विभासि पुरो — भव शंकर देशिक मे शरणम्॥

७. गुरु पुंगव पुंगव केतन ते — समता मयतां नहि कोऽपि सुधीः।
शरणागत वत्सल तत्वनिधे — भव शंकर देशिक मे शरणम्॥

८. विदिता न मया विषदैक कला — न च किंचन कांचन मस्ति गुरो।
द्रुतमेव विधेहि कृपां सहजां — भव शंकर देशिक मे शरणम्॥

In Public domain. Digitization Muthulakshmi Research Academy

॥ मन्त्र पुष्पम् ॥

१. योऽपां पुष्पं वेद। पुष्पवान् प्रजावान् पशुमान् भवति। चन्द्रमा वा अपां पुष्पम्। पुष्पवान् प्रजावान् पशुमान् भवति। य एवं वेद। योऽपा मायतनं वेद। आयतनवान् भवति॥

२. अग्नि र्वा अपा मायतनम्। आयतनवान् भवति। योऽग्ने रायतनं वेद। आयतनवान् भवति। आपो वा अग्ने रायतनम्। आयतनवान् भवति। य एवं वेद। योऽपा मायतनं वेद। आयतनवान् भवति॥

३. वायु र्वा अपा मायतनम्। आयतनवान् भवति। यो वायो रायतनम् वेद। आयतनवान् भवति। आपो वै वायो रायतनम्। आयतनवान् भवति। य एवं वेद। योऽपा मायतनं वेद। आयतनवान् भवति॥

४. असौ वै तपन्नपा मायतनम्। आयतनवान् भवति। योऽमुष्य तपत आयतनं वेद। आयतनवान् भवति। आपो वा अमुष्य तपत आयतनम्। आयतनवान् भवति। य एवं वेद। योऽपामायतनं वेद। आयतनवान् भवति॥

५. चन्द्रमा वा अपा मायतनम्। आयतनवान् भवति। यश्चन्द्रमस आयतनं वेद। आयतनवान् भवति। आपो वै चन्द्रमस आयतनम्। आयतनवान् भवति। य एवं वेद। योऽपा मायतनं वेद। आयतनवान् भवति॥

६. नक्षत्राणि वा अपामायतनम्। आयतनवान् भवति। यो नक्षत्राणा मायतनं वेद। आयतनवान् भवति। आपो वै नक्षत्राणा मायतनम्। आयतनवान् भवति। य एवं वेद। योऽपा मायतनं वेद। आयतनवान् भवति॥

७. पर्जन्यो वा अपा मायतनम्। आयतनवान् भवति। यः

In Public domain. Digitization Muthulakshmi Research Academy

पर्जन्यस्यायतनं वेद। आयतनवान् भवति। आपो वै पर्जन्यस्यायतनम्। आयतनवान् भवति। य एवं वेद। यो ऽपा मायतनं वेद। आयतनवान् भवति॥

८. संवत्सरो वा अपा मायतनम्। आयतनवान् भवति। यत्सं वत्सरस्यायतनं वेद। आयतनवान् भवति। आपो वै सं वत्सर स्यायतनं वेद। आयतनवान् भवति। य एवं वेद। यो ऽप्सु नावं प्रतिष्ठितां वेद। प्रत्येव तिष्ठति॥

९. राजाधि राजाय प्रसह्यसाहिने। नमो वयं वैश्रवणाय कुर्महे। समेकामान्कामकामाय मह्यम्। कामेश्वरो वैश्रवणो ददातु। कुबेराय वैश्रवणाय। महाराजाय नमः॥

१०. न कर्मणा न प्रजया धनेन त्यागेनैके अमृतत्वमानशुः।
परेण नाकं निहितं गुहायां विभ्राजदेतयद्यतयो विशन्ति॥
वेदान्त विज्ञान सुनिश्चितार्थाः सन्यास योगा द्यतय श्शुद्ध सत्वाः।
ते ब्रह्म लोकेतु परान्तकाले परामृता त्परिमुच्यन्ति सर्वे॥
दह्रं विपाप्मं परमे ऽश्म भूतं यत्पुण्डरीकं पुरमध्य संस्थम्।
तत्रापि दह्रं गगनं विशोक स्तस्मिन् यदन्त स्तदुपासि तव्यम्॥
यो वेदादौ स्वरः प्रोक्तो वेदान्ते च प्रतिष्ठितः।
तस्य प्रकृति लीनस्य यः परस्स महेश्वरः॥
यो वैतां ब्रह्मणो वेद। अमृतेनावृतां पुरीम्।
तस्मै ब्रह्म च ब्रह्मा च आयुः कीर्तिं प्रजान्ददुः॥

॥ ओं नमो ब्रह्मणे (त्रिवारं) ॥

नमो ब्रह्मणे नमो अस्त्वग्नये नमः पृथिव्यै नम ओषधीभ्यः। नमो वाचे नमो वाचस्पतये नमो विष्णवे बृहते करोमि॥ ओं शान्तिः शान्तिः शान्तिः॥

★★★

In Public domain. Digitization Muthulakshmi Research Academy

In Public domain. Digitization Muthulakshmi Research Academy

In Public domain. Digitization Muthulakshmi Research Academy

In Public domain. Digitization Muthulakshmi Research Academy

In Public domain. Digitization Muthulakshmi Research Academy



Sree Vinayaka Mandir Committee

AB-Block, Vinayaka Mandir Marg, Sarojini Nagar,
New Delhi-110023 (India) Tel. : 91-11-24670924, 24105525
E-mail : info@vinayaka.org, svmc1961@gmail.com
Website : //www.vinayaka.org